# A DESCRIPTIVE CATALOGUE

OF THE

# SANSKRIT MANUSCRIPTS

OF THE

## GOVERNMENT ORIENTAL MANUSCRIPTS LIBRARY, MADRAS.

BY THE LATE

M. SESHAGIRI SASTRI, M.A.,

CURATOR, GOVERNMENT ORIENTAL MANUSCRIPTS LIBRARY, AND PROFESSOR OF SANSKRIT AND COMPARATIVE PHILOLOGY, PRESIDENCY COLLEGE, ETC.

*PREPARED UNDER THE ORDERS OF THE GOVT. OF MADRAS.*

VOL. I.—VEDIC LITERATURE

*FIRST PART*

MADRAS:

PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS.

1901.

# PREFATORY NOTE.

THIS catalogue was prepared and made ready for publication under the orders of the Government of Madras by the late Professor M. Seshagiri Sastriar, M.A., some time before his death; and it is now published as prepared by him, although it covers only a part of the Manuscripts on Vedic Literature to be found in this Library. The following table explains the principle of transliteration adopted in the catalogue:—

| | | Consonants. | Vowels | Diphthongs. |
|---|---|---|---|---|
| Gutturals | ... | k kh g gh n h h | a ā | ē (e) ai |
| Palatals ... | ... | c ch j jh ñ y ś | i ī | |
| Linguals | .. | t th ḍ ḍh n r s | ṛ rī | |
| Dentals ... | ... | t th d dh n l s | l lī | |
| Labials ... | ... | p ph b bh m v ḥ | u ū | ō (o) au |

M. RANGACHARYA, M.A.

# CONTENTS.

## CLASS I —VEDIC LITERATURE.

### I —SAMHITĀ AND BRĀHMAṆA.

#### 1 —The Rg Vēda (1).


| Name of the work | Number | Page |
|---|---|---|
| Rgvēda Samhitā ... ... . | 1 to 7 | 1, 2, 6, 7, 8, 10 |
| Rgvēdapadapāthah ... ... . ... .. | 8 to 15 | 26, 27, 28, 29, 30, 31 |
| Rgvēdabhāsyam (Vēdārthaprakāśah) ... . . . | 16 | 32 |
| Śrīsūktam ... ... ... .. . . | 17 to 22 | 34, 37, 38, 39, 42 |
| Śrīsūktabhasyam ... .. . | 23 to 27 | 43, 46, 51, 52 |
| Śrīsūktavyākhyā . ... ... ... . ... | 28 to 30 | 53, 55, 56 |
| Rgbhāsyam ... ... ... ... ... . | 31 | 57 |
| Rgvēda-Brāhmanam . ... ... .. | 32 to 34 | 59, 62, 63 |
| Rgvēda-Brāhmanabhāsyam ... ... ... ... ... | 35 to 37 | 64, 67, 68 |
| Rgvēdāranyakam (Rgvēdārnnam) ... .. | 38 to 40 | 69, 70, 71 |


#### 2.—The Sāma Vēda (71)


| Name of the work | Number | Page |
|---|---|---|
| Sāmavēdasamhitā and Rkpāthah ... ... .. .. | 41 to 45 | 78, 102, 103, 104 |
| Samavedagānam Prakrtih ... ... . . . | 46 | 104 |

Index ... ... ... ... .. ... ... .. ... 105

# A DESCRIPTIVE CATALOGUE

OF THE

# SANSKRIT MANUSCRIPTS.

---

## CLASS I.—VEDIC LITERATURE.

## i. Saṁhitā and Brāhmaṇa—1. The Ṛg Vēda.

---

### No 1. ऋग्वेदसंहिता.

### ṚGVĒDA SAṀHITĀ

Substance, paper Size, 13 × 8 inches Pages, 942 Lines, 22 on a page Character, Telugu. Appearance, old In good condition.

Contains the eight Astakas complete

The Saṁhitā portion of the Ṛgvēda is divided in two ways: it is divided into eight parts, each of which is called Astaka. Each Astaka is sub-divided into eight Adhyāyas, whence the name Astaka, which again are sub-divided into Vargas; and these, again into Ṛcas The number of Ṛcas in a Varga and the number of Vargas in an Adhyāya are not the same and are various The Samhitā is again divided into ten Manḍalas; each Mandala is composed of a number of Anuvākas which are sub-divided into Sūktas composed of Ṛcas. The codex under notice and all the manuscripts of this Library containing the work, adopt the Astaka division. The text in this manuscript is not accented. With regard to the accentuation see the remarks on page 3 A list of the authors of the Ṛgvēda Samhitā, which will be of much use to the student of history and mythology, is given on pages 11—24

The Saṁhitā has been published completely by Th. Aufrecht in Roman letters, 1861—3; the second edition was published in 1877.

F M Müller edited the Samhitā and the Pada texts in parallel volumes in 1873, and both the texts with Sāyana's commentary and a copious verbal index in six volumes (1849—74) Complete translations of the Samhitā have been published by Alfred Ludwig (Prag. 1876) and Hermann Grassman (Leipzig, 1876—77). The latter has published a valuable index under the designation of Worterbuch zum Rigvēda An English translation of the whole Samhitā has been printed by Griffith recently

**Beginning :**

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥

**End :**

समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सु (स)हासति ॥ 49 ॥ हरिः ओं ॥

From a passage [1] occurring in a Kārika it is said that the text of the Śākala Śākhā of the Rgvēda ends with the Rk समानी व आकूतिः . . . . and that of the Bāskala Śākhā, with the Rk तच्छं योः . . . But this opinion is refuted by Dr Bhandarkar in his Report for the three years 1895 to 1897.

---

## No 2. ऋग्वेदसंहिता.

## RGVĒDA SAṀHITĀ

Substance, palm-leaf Size, 14 × 1½ inches Pages, 386 Lines, 7 on a page. Character, Telugu. Appearance, old. Injured

Contains the 3rd Astaka (pages 1—126), the 1st Astaka (pages 127—288) and the 2nd Aṣṭaka, Adhyāyas 1—6 (pages 289—386).

Accented.

---

[1] शाकलानां समानी व इत्यृचान्त्याहुतिर्भवेत् ।
बाष्कलानां तु तच्छंयोरित्यृचान्त्याहुतिर्भवेत् ॥

The following is a scheme of Vēdic accents which deserves the attention of foreign readers for understanding the general principles of the Vēdic svaras in the light of music :—


*Udātta*, and *Pracaya*, i.e., *Anudātta* following *Svarita* } .. not marked.

*Anudātta* preceding the *Udātta* and *Svarita*. } .. marked as —

*Svarita* .. .. .. .. do. |

There are three *Svaras* or accents in the Vedas: the *Udātta*, 'acute,' the *Anudātta*, 'grave,' and the *Svarita*, 'toned.' When more than one *Anudātta* precede an *Udātta*, all but the last are often sounded lower. The 1st *Anudātta* following an Udātta becomes *Svarita*; and all the rest are sounded like the *Udātta* and called *Pracayas*. If we compare the above accents with the tones of a musical gamut, we can know the exact sounds of those accents. Let the *Udātta* be represented by any key on the piano and be marked as *C*, and स *sa* according to the Hindu method; then the two sounds of the *Anudātta* will be marked as *B* and नि *ni*, and *G* and प *pa*, respectively. The *Svarita* will be sounded as *C* sharp and रि *ri*.[2] The *Pracaya svara*, as it is pronounced by the Brahmans of the *Taittirīya Śākhā* and the Ṛgvēda, is identical with the *Udātta*, and therefore is equal to *C* and स *sa*. A long *Svarita* in the Ṛgvēda is split into two long sounds—the first of which is sounded as *Udātta* and the second, as *Svarita*.


नि स्स सा री सा नि सा रि सा नि स्स रि नी स



अ ग्नि मी - ळे पु रो हिं तं य ज्ञ स्यं दे व

[2] It is called *śuddha ṛṣabha* by the Hindus.


नि स्स सा री  सा सा री सा स त्नि सां रि सा



ऋ त्वि जं -  हो तां - रं र त्न धा॑ तं मन्

Ṛgvēda, I 1 1.

पा प नि स्सा नी स सा री नी



चो द यि त्री सू नृ तां नां

सा सा री सा स स नी सा



चे त ती सु म तीं नाम्

*Ibid.*, I. 3. 4

This system of accentuation is not scientific, nor does it prevail in many parts of India such as the northern countries and Malabar It differs considerably from the mode of accentuation adopted in the Sāma Vēda in reciting the original hymns or ṛks taken from the Ṛgvēda From the musical notation given above, it is seen that the sound of the Svarita is higher by one note than the Udātta, and this is wrong as the Udātta must be raised above the other svaras The Anudātta being lower than the Udātta, the Svarita must be higher than the Anudātta and lower than the Udātta, and so must intervene between them In any case we have simply to mark only the Udātta, and the positions of the remaining svaras can be settled.

There is a Bhūrja manuscript of the Rgvēda which is more than five hundred years old and was discovered by Dr Buhler In the manuscript the Udātta alone is marked, and that by a perpendicular stroke; and the same is the case with one of the two schools of the Maitrāyanī samhita (Weber's *Hist of Ind Lit.*, p. 314). There are two manuscripts in the Library in which this notation is adopted This notation is more scientific than the existing one.

Generally the same accentuation is adopted both in the Rgvēda and the Yajur Vēda The whole of the ten Mandalas of the Rgvēda, and the Samhitā and the major portions of the Brāhmanas of the Yajur Vēdas are accented; and many of the remaining Brāhmanas and generally the Upanisads are not accented

**Beginning** of Astaka III:

हरिः ओं ॥ प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः । परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥

**End:**

स क्षेपयत् स पोषयद्भुवद्राजस्य सातये उतैधि पृत्सुनो वृधे ॥ 27 ॥ . . . . इदमुत्यत् सम्यक्स्रवन्ति सुप्रतीके षट् ॥

For an explanation of this mnemonical formula see p. 11

**Colophon**:—तृतीयाष्टकः समाप्तः ॥

**Beginning** of Astaka I:

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजं । होतारं रत्नधातमम् ॥

**End:**

(Last two leaves in this Astaka are wanting )

प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वां । प्रैष्युर्न विद्वान् ॥ 22 ॥

**Beginning** of Astaka II :

हरिः ओं ॥ प्र वः पान्तं रघुमन्यु वोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वं । दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥

**End:**

ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥ 32 ॥ हरिः ओं ॥

**Colophon:**—द्वितीयाष्टके षष्ठोऽध्यायः ॥

---

No 3. ऋग्वेदसंहिता.

RGVĒDA SAMHITĀ.

Substance, palm-leaf. Size, 14 × $1\frac{3}{4}$ inches Pages, 69. Lines, 5 on a page. Character, Nandināgarī Appearance, old. Injured.

Contains 1–2 Adhyāyas in the 1st Astaka.

Accented

**Beginning:**

हरिः ओं ॥ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥

**End:**

इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥ हरिः ओं ॥

*  *  *  *

अयं देवायां व यो व यन्ति यच्चिद्वि शश्वता शश्वदिन्द्रोऽष्टौ ॥

For an explanation of this mnemonical formula see p 11

**Colophon**:—इति प्रथमाष्टके द्वितीयोऽध्यायः ॥

---

### No 4. ऋग्वेदसंहिता.

### RGVĒDA SAṀHITĀ

Substance, palm leaf Size, $15\frac{1}{2} \times 1\frac{1}{2}$ inches Pages, 111 Lines, 7 on a page Character, Telugu Appearance, old Injured.

The first folio is marked 34

Contains Adhyāyas 2—8 in the 3rd Astaka The 8th Adhyāya, according to the MS Nos 1 and 2 contains 27 Vargas, while the printed books and this manuscript have 26 Vargas, and the 27th is added to the next Adhyāya.

**Beginning**:

हरिः ओं ॥ इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि । तितिक्षन्ते अन्त (भि)शस्तिं जना(ना)मिन्द्र त्वदा कश्चन हि प्रकेतः ॥

**End**:

त्वामग्ने प्रदिव आहुतं घृतैस्सुम्नायवस्सुषमिधा समीधिरे । स वावृधान ओषधिभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥ 26 ॥ हरिः ओं ॥

---

### No 5. ऋग्वेदसंहिता.

### RGVĒDA SAṀHITĀ.

Substance, palm-leaf Size, $12\frac{1}{2} \times 1\frac{1}{2}$ inches. Pages, 96. Lines, 5 on a page. Character, Nandināgari. Appearance, old Injured.

Sixteen folios are wanting in the beginning Begins in folio **17** Contains the 6th Astaka, from 31st Varga of the 1st Adhyāya to the 13th Varga of the 4th Adhyāya

**Beginning:**

यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः । हव्या वा वेविषद्विषः ॥

**End:**

त्वन्नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः । त्वन्न इन्द्र ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥ 13 ॥

---

## No 6. ऋग्वेदसंहिता.

## ṚGVĒDA SAṀHITĀ

Substance, paper Size, $9\frac{3}{4} \times 8\frac{3}{4}$ inches Pages, 8. Begins on page 65 Lines, 12 on a page Character, Telugu. Appearance, old. In good condition.

| Contains | | | | | | | |
|---|---|---|---|---|---|---|---|
| (1) | Astaka | 2, | Adhyāya | 8, | Vargas | 13, 14, 15 |
| (2) | Do | 6, | do | 7, | do | 10. |
| (3) | Do. | 8, | do | 7, | do | 15 |
| (4) | Do | 7, | do | 8, | do | 20. |
| (5) | Do. | 3, | do | 4, | do. | 10. |

Pages 1 to 63 contain the Aśvamēdha portion of the Srauta Sūtra.

**Beginning** of (1):

भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जर ॥ . . . . यैावनानि महयसि जिग्युषामिव दुन्दुभिः । शकुन्तक प्रदक्षिणं शतपत्राभिनो वद ॥

This is an apocryphal hymn mentioned by Professor Max Muller in the Preface to his Rgvēda, Vol. II. It is added at the end of a manuscript consulted by him after the 12th Varga of the 8th Adhyāya of the 2nd Astaka.

Then follows the last hymn of the 12th Varga, the 13th, 14th and 15th Vargas of the 8th Adhyāya of the 2nd Astaka The 11th and 12th Vargas contain hymns to be recited on hearing any unpleasant cries of birds as stated in the commentary. They are also recited in the marriage ceremony on the occasion of the bride going to the father-in-law's house and are called Sumangala Sūkta. They are addressed to the bird Kapiñjara, a kind of partridge, which is supposed to represent the god Śiva and Indra, and are to be recited with the other passages. The apocryphal passage beginning with भद्रं वद दक्षिणतः is addressed to the same bird कपिञ्जर.

(3) contains a Khila or apocryphal hymn called Rātrisūkta which is printed in the Preface to Vol. VI, Rgvēda, by Professor Max Muller. The passage occurs at the end of X, 127 in two of the manuscripts consulted by him. This Śūkta is a hymn addressed to the Night deity and is called Rātrisūkta and, according to the quotation made from the Āranyaka, should be recited at a sacrifice for removing the effects of evil dreams. It is referred to also in Asva-Grhya Pariś, 1. The text in the manuscript under notice is slightly different from what is printed by him. After the 4th Ṛk, occurs तामग्निवर्णां तपसा which is the 12th in the text printed by him. The next hymn is दुर्गेषु विषमे घोरे, which occurs as the 9th in the printed text. Then follow the hymns दुर्गादुर्गेषु स्थानेषु and रात्री कुशिकस्सौभरः which are the 13th and 14th in the latter text with which the Sūkta ends. But the text in the manuscript is then followed by the following hymns, उलूकयातुं VII, 104—22; रक्षाणो अग्ने IV, 3—14; पिशङ्ग भृष्टिन् I, 133—5; बृहत्साम,.अहरहर्वावते, हैवास्मै भवति. After this occur the five hymns of the Sūkta

128 of X, which constitute the 15th Varga of the 7th Adhyāya of the VIII Astaka.

---

## No 7. ऋग्वेदसंहिता.
## RGVĒDA SAMHITĀ

Substance, palm-leaf. Size, 14 × 1½ inches Pages, 254 Lines, 6 on a page Character, Nandināgarī Appearance, old Injured; first two leaves torn at the ends Accented

Contains the 8th Astaka complete

The first leaf is wanting.

As can be seen from the following colophons at the end of the 1st and the 7th Adhyāyas इति श्रीशाकलसंहितायामष्टमाष्टके-प्रथमोऽध्यायः and इति श्रीशाकलसं . . . . सप्तमोऽध्यायः, the text given in the manuscript under notice professes to belong to the Śākala Śākhā of the Ṛgvēda Samhitā *Vide* p. 2 and the foot-note.

**Beginning:**

(Third Varga of the I Adhyāya of the 8th Astaka)

जगृभ्मा ते स्वायुधं सुब्रह्माणं सनद्वाजमश्वावन्तं पञ्च ।

जगृभ्मा ते दक्षिणमिन्द्रहस्तं वसूयवो वसुपते वसूनां । विद्मा हि त्वा गोपतिं शूरगोनामस्मभ्यं चित्रं वृषणं रयिन्दाः ॥

**End:**

समानी व आकूतिस्समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ॥ 49 ॥—॥

अग्निर्वै देवानामवमोविष्णुः । संसमिद्युवसे वृषन् । ऋतं च सत्यं चा-भीद्धात् । . . . . . अयं हि ते अमर्त्यः । त्वं चिदत्रि-मृजुरं ॥ — ॥ त्वांचिदींखयन्ती रश्मिभ्यामात्वाहार्षमपश्यन्त्वा नव ॥

Colophon:—इत्यष्टमाष्टकेऽष्टमोऽध्यायः समाप्तः ।

The first passage of the extract is a kind of index giving the first few words, and the number, of the Rcas in the Varga Such an index is added to many of the Vargas in this codex Another peculiar feature is that an index is added at the end of each Adhyāya which gives the initial two or three words of every Varga, beginning from the 1st Varga of the next Adhyāya, and going backwards up to the 1st Varga of the Adhyāya For instance, at the end of the 8th Adhyaya, the index begins with the first four words of the 1st Varga of the next Adhyāya, viz, the Brāhmana, which begins as अग्निर्वै देवानामवमो विष्णुः (*Vide* p 10). Next comes the first few words of the last Varga in the 8th Adhyāya, *i e*, of the 49th Varga, then of the 48th Varga and so on, till the 1st Varga

Then follows another index which gives the first words of the 1st, 11th, 21st, 31st, 41st, &c., Vargas The number of Vargas remaining over the decennial number, *i e*, over 10, 20, 30, 40, 50, &c, is also added For example in the 8th Adhyāya, the words त्यंचित्, ईखयन्तीः, अक्षीभ्यां, आत्वाहार्ष, अपश्यन्त्वा are the initial words of the 1st, 11th, 21st, 31st and 41st Vargas; and नव or 9 at the end shows that there are nine Vargas over 40, making up a total of 49 Vargas Similar mnemonical formalæ occur in the Yajur Vēdas also.

The following list of the authors and authoresses of the Sūktas of the Rgvēda, which is of much interest to the students of history and mythology, is given in alphabetical order The same list is printed also in Vol VI of Professor Max Muller's Rgvēda.

| | म. | सू. |
|---|---|---|
| अंहोमुक् वामदेव्यः ... | 10 | 126 |
| अक्षः मौजवान् ... | 10 | 34 |
| अगस्त्यः ... | 1 | 165 to 190 |
| अगस्त्यः विषशङ्कावान् ... | 1 | 191 |
| अगस्त्यस्य स्वसा बन्ध्वदीनां माता ... | 10 | 60 |
| अग्नयः धिष्ण्याः ऐश्वराः ... | 9 | 109 |

| | म. | सू. |
|---|---|---|
| अग्निः ... | 8 | 102 |
| | 9 | 106 |
| | 10 | 124 |
| अग्निः चाक्षुषः .. | 9 | 106 |
| अग्निः(तापसः) ... | 10 | 141 |
| अग्निः पावकः ... | 10 | 140 |
| अग्नियुतः (स्थौरः) ... | 10 | 116 |
| अग्नियूपः स्थौरः | 10 | 116 |
| अग्निवरुणसोमानां निवहः ... | 10 | 124 |
| अग्निः सौचीकः | 10 | 51 to 53, 79, 80 |
| अघमर्षणः (माधुच्छन्दसः) .. | 10 | 190 |
| अङ्गः (औरवः) ... | 10 | 138 |
| अजमीळ्हः सौहोत्रः | 4 | 43, 44 |
| अत्रिः ... ... | 5 | 27, 37, to 43, 76, 77, 83 to 86 |
| | 9 | 67, 86 |
| अत्रिः (साङ्ख्यः). | 10 | 143 |
| अदितिः ... | 4 | 18 |
| अदितिः दाक्षायणी | 10 | 72 |

| | म. | सू. |
|---|---|---|
| अनानतः पारुच्छेपिः .. | 9 | 111 |
| अनिलः (वातायनः) ... | 10 | 168 |
| अन्तेवासी ब्रह्मचारी ... | 1 | 179 |
| अन्धीगुः श्यावाश्विः | 9 | 101 |
| अपालात्रेयी ... | 8 | 91 |
| अप्रतिरथः(ऐन्द्रः) | 10 | 103 |
| अभितपाः सौर्यः | 10 | 37 |
| अभीवर्तः .. | 10 | 174 |
| अमहीयुः ... | 9 | 61 |
| अम्बरीषः ... | 9 | 98 |
| अम्बरीषः वार्षागिरः राजर्षिः ... | 1 | 100 |
| अयास्यः ... | 9 | 44 to 46 |
| | 10 | 67, 68 |
| अरिष्टनेमिः तार्क्ष्यः | 10 | 178 |
| अरुणाः वैतहव्यः | 10 | 91 |
| अर्चन् हैरण्यस्तूपः | 10 | 149 |
| अर्चनाना .. | 8 | 42 |
| अर्चनाना आत्रेयः | 5 | 63, 64 |
| अर्बुदः (काद्रवेयः) ... | 10 | 94 |

| | म. | सू. |
|---|---|---|
| अवत्सारः ... | 9 | 53 to 60 |
| अवत्सारः काश्यपः | 5 | 44 |
| अवस्युरात्रेयः ... | 5 | 31, 75 |
| अश्वमेधः भारतः | 5 | 27 |
| अश्वसूक्ती काण्वायनः ... | 8 | 14, 15 |
| अष्टकः (वैश्वामित्रः) | 10 | 104 |
| अष्टादंष्ट्रः (वैरूपः) ... | 10 | 111 |
| असितः काश्यपः. | 9 | 5 to 24 |
| आकृष्टा माषाः ... | 9 | 86 |
| आत्मा ... | 3 | 26 |
| आयुः काण्वः ... | 8 | 52 |
| आसङ्गः प्रायोगिः. | 8 | 1 |
| इटः (भार्गवः) ... | 10 | 171 |
| इध्मवाहः दार्ढच्युतः ... | 9 | 26 |
| इन्द्रः ... | 1 | 165, 170 |
| | 4 | 18, 26 |
| | 8 | 100 |
| | 10 | 28 |
| इन्द्रः (मुष्कवान्). | 10 | 38 |
| इन्द्रः वैकुण्ठः ... | 10 | 48 to 50 |
| इन्द्रप्रमतिः (वासिष्ठः) .. | 9 | 97 |
| इन्द्रमातरः देवजामयः ... | 10 | 153 |
| इन्द्राणी ... | 10 | 145 |
| इरिम्बिठिः काण्वः | 8 | 16 to 18 |
| इषः आत्रेयः ... | 5 | 7, 8 |
| उचथ्यः ... | 9 | 50 to 52 |
| उत्कीलः कात्यः | 3 | 15, 16 |
| उपमन्युः वासिष्ठः | 9 | 97 |
| उपस्तुतः वार्ष्टिहव्यः ... | 10 | 115 |
| उरुक्षयः आमहीयवः ... | 10 | 118 |
| उरुचक्रिरात्रेयः ... | 5 | 69, 70 |
| उर्वशी ... | 10 | 95 |
| उलः (वातायनः) | 10 | 186 |
| उशना ... | 9 | 87 to 89 |
| उशना (काव्यः) | 8 | 84 |
| ऊरुः ... | 9 | 108 |

| | म. | सू. |
|---|---|---|
| ऊर्ध्वकृशनः (यामायनः) .. | 10 | 144 |
| ऊर्ध्वग्रावा आर्बुदिः ... | 10 | 175 |
| ऊर्ध्वनाभा (ब्राह्मः) ... | 10 | 109 |
| ऊर्ध्वसद्मा ... | 9 | 108 |
| ऋजिश्वा ... | 6 | 49 to 52 |
| | 9 | 98,108 |
| ऋणञ्चयः ... | 9 | 108 |
| ऋषभः वैराजः शाक्वरो वा ... | 10 | 166 |
| ऋषभः वैश्वामित्रः. | 3 | 13, 14 |
| | 9 | 71 |
| एकद्यूः नौधसः... | 8 | 80 |
| एवयामरुदात्रेयः... | 5 | 87 |
| कक्षीवान् ... | 9 | 74 |
| कक्षीवान् दैर्घतमसः औशिजः | 1 | 116 to 126 |
| कण्वः ... | 9 | 94 |
| कण्वः घौरः ... | 1 | 36 to 43 |
| कतः वैश्वामित्रः... | 3 | 17, 18 |
| कपोतः नैर्ऋतः ... | 10 | 165 |

| | म. | सू. |
|---|---|---|
| कर्णश्रुद्वासिष्ठः ... | 9 | 97 |
| कलिः प्रागाथः ... | 8 | 66 |
| कवषः ऐलूषः ... | 10 | 30 to 34 |
| कविः ... | 9 | 75 to 79 |
| कविः भार्गवः ... | 9 | 47 to 49 |
| कश्यपः ... | 9 | 64, 67 91, 92 113, 114 |
| कश्यपः मारीचः... | 1 | 99 |
| | 8 | 29 |
| कुत्सः ... | 9 | 97 |
| कुत्सः आङ्गिरसः | 1 | 94 to 98, 101 to 104, 106 to 115 |
| कुत्सः आप्त्यः ... | 1 | 105 |
| कुमारः आग्नेयः ... | 7 | 102 |
| कुमारः आत्रेयः . | 5 | 2 |
| कुमारः (यामायनः) | 10 | 135 |
| कुरुसुतिः काण्वः | 8 | 76 to 78 |

| | म. | सू. |
|---|---|---|
| कुल्मलबर्हिषः (शैलूषिः) . | 10 | 126 |
| कुशिकः .. | 3 | 31 |
| कुशिकः (सौभरः) | 10 | 127 |
| कुसीदी काण्वः .. | 8 | 81 to 83 |
| कूर्मः गार्त्समदः ... | 2 | 27 to 29 |
| कृतयशाः ... | 9 | 108 |
| कृत्नुः भार्गवः ... | 8 | 79 |
| कृशः (काण्वः) ... | 8 | 55 |
| कृष्णः .. ... | 8 | 85, 86 |
| | 10 | 42 to 44 |
| कृष्णः (द्युम्नीकः) | 8 | 87 |
| केतुः आग्नेयः ... | 10 | 156 |
| गयः आत्रेयः ... | 5 | 9, 10 |
| गयः प्लातः ... | 10 | 63, 64 |
| गर्गः ... | 6 | 47 |
| गविष्ठिरः आत्रेयः | 5 | 1 |
| गातुरात्रेयः ... | 5 | 32 |
| गाथी ... ... | 3 | 19 to 22 |
| गृत्समदः ... | 2 | 2, 3, 8 to 43 |
| | 9 | 86 |

| | म. | सू. |
|---|---|---|
| गृत्समदः आङ्गिरसः शौनहोत्रः पश्चाद्भार्गवः शौनकः ... | 2 | 1 |
| गृहपत्यग्निः सहसः सुतः ... | 8 | 102 |
| गोधा ... ... | 10 | 134 |
| गोपवनः आत्रेयः. | 8 | 73, 74 |
| गोतमः ... | 9 | 31, 67 |
| गोतमः (राहूगणः) | 1 | 74 to 93 |
| गौरिवीतिः ... | 9 | 108 |
| | 10 | 73, 74 |
| गौरिवीतिः शाक्त्यः ... | 5 | 29 |
| गोषूक्ती अश्वसूक्ती काण्वायनौ ... | 8 | 14, 15 |
| घर्मः तापसः ... | 10 | 114 |
| घर्मः सौर्यः ... | 10 | 181 |
| घोरः आङ्गिरसः | 3 | 36 |
| घोषा काक्षीवती .. | 10 | 39, 40 |
| चक्षुः मानवः ... | 9 | 106 |
| चक्षुः सौर्यः ... | 10 | 158 |
| चित्रमहाः (वासिष्ठः) ... | 10 | 122 |

| | म | सू. |
|---|---|---|
| च्यवनो भार्गवः ... | 10 | 19 |
| जमदग्निः ... | 3 | 62 |
| | 9 | 62, 65 67 |
| | 10 | 110, 167 |
| जमदग्निः भार्गवः ... | 8 | 101 |
| जयः ऐन्द्रः ... | 10 | 180 |
| जरत्कर्ण ऐरावतः सर्पः ... | 10 | 76 |
| जुहूः ब्रह्मजाया ... | 10 | 109 |
| जेता माधुच्छन्दसः | 1 | 11 |
| तान्वः (पार्थ्य ) | 10 | 93 |
| तिरश्चीः ... | 8 | 95, 96 |
| त्रपुमूर्धा बार्हस्पत्यः | 10 | 182 |
| त्रसदस्युः पौरुकुत्स्यः .. | 4 | 42 |
| | 5 | 27 |
| त्रसदस्युः ... | 9 | 110 |
| त्रितः ... ... | 9 | 33,34, 102 |
| त्रितः ... ... | 10 | 1 to 7 |
| त्रितः आप्त्यः ... | 1 | 105 |
| | 8 | 47 |

| | म. | सू. |
|---|---|---|
| त्रिशिराः त्वाष्ट्रः .. | 10 | 8, 9 |
| त्रिशोकः (काण्वः) | 8 | 45 |
| त्रैवृष्णा पौरुकुत्स्यः ... | 5 | 27 |
| त्र्यरुणः ... | 9 | 110 |
| त्र्यरुणः पौरुकुत्स्यः | 5 | 27 |
| त्वष्टा (गर्भकर्ता) | 10 | 184 |
| दक्षिणा प्राजापत्या | 10 | 107 |
| दमनः यामायनः | 10 | 16 |
| दिव्यः .. ... | 10 | 107 |
| दीर्घतमाः औचथ्यः | 1 | 140 to 164 |
| दुवस्युः वान्दनः .. | 10 | 100 |
| दुर्मित्रः कौत्सः सुमित्रः ... | 10 | 105 |
| दृळ्हच्युतः आगस्त्यः .. | 9 | 25 |
| देवरातः कृत्रिमो वैश्वामित्रः .. | 1 | 24 |
| देवमुनिः (ऐरम्मदः) .. | 10 | 146 |
| देवलः ... | 9 | 5 to 24 |
| देवव्रतः भारतः... | 3 | 23 |

| | म. | सू. |
|---|---|---|
| देवश्रवाः भारतः | 3 | 23 |
| देवश्रवाः यामायनः | 10 | 17 |
| देवाः | 10 | 51, 53 |
| देवातिथिः (काण्वः) | 8 | 4 |
| देवापिरार्ष्टिषेणः | 10 | 98 |
| द्युतानः मारुतः | 8 | 96 |
| द्युम्नः विश्वचर्षणिः | 5 | 23 |
| द्वितः आप्त्यः | 9 | 103 |
| द्वितः मृक्तवाहाः आत्रेयः | 5 | 18 |
| धरुणः आङ्गिरसः | 5 | 15 |
| ध्रुवः | 10 | 173 |
| नभः प्रभेदनो वैरूपः | 10 | 112 |
| नरः | 6 | 35, 36 |
| नहुषः (मानवः) | 9 | 101 |
| नाभाकः काण्वः | 8 | 39 to 42 |
| नाभानेदिष्ठः मानवः | 10 | 61, 62 |
| नारदः (काण्वः) | 8 | 13 |
| नारायणः | 10 | 90 |
| निध्रुविः काश्यपः | 9 | 63 |
| नीपातिथिः काण्वः | 8 | 34 |
| नृमेधः | 8 | 89, 90, 98, 99 |
| नृमेधः | 9 | 27, 29 |
| नेमः भार्गवः | 8 | 100 |
| नोधाः | 9 | 93 |
| नोधाः | 8 | 88 |
| नोधा गौतमः | 1 | 58 to 64 |
| पणयः असुराः | 10 | 128 |
| पतङ्गः प्राजापत्यः | 10 | 177 |
| पराशरः | 9 | 97 |
| पराशरः शाक्त्यः | 1 | 65 to 73 |
| परुच्छेपः दैवोदासिः | 1 | 127 to 139 |
| पर्वतः काण्वः | 8 | 12 |
| पर्वतनारदौ | 9 | 104, 105 |
| पवित्रः | 9 | 67 |
| पवित्रः | 9 | 73, 83 |
| पायुः | 10 | 87 |
| पायुः भारद्वाजः | 6 | 75 |

| | म. | सू. |
|---|---|---|
| पावको बार्हस्पत्यः | 8 | 102 |
| पुनर्वत्सः काण्वः | 8 | 7 |
| पुरुमील्हः ... | 8 | 71 |
| पुरुमीळ्हः सौहोत्रः | 4 | 43 44 |
| पुरुमेधः ... | 8 | 89, 90 |
| पुरुहन्मा ... | 8 | 70 |
| पुरूरवाः (ऐलः) | 10 | 95 |
| पुष्टिगुः काण्वः ... | 8 | 50 |
| पूतदक्षः ... | 8 | 94 |
| पूरणः वैश्वामित्रः | 10 | 160 |
| पूरुः आत्रेयः ... | 5 | 16, 17 |
| पृथुः वैन्यः ... | 10 | 148 |
| पृश्नयः अजाः ... | 9 | 86 |
| पृषध्रः काण्वः ... | 8 | 46 |
| पौरः आत्रेयः ... | 5 | 73, 74 |
| प्रगाथः काण्वः ... | 8 | 1, 10, 48, 62 to 65 |
| प्रगाथः घौरः ... | 8 | 1 |
| प्रचेताः ... | 10 | 164 |
| प्रजापतिः ... | 9 | 101 |
| प्रजापतिः (परमेष्ठी) ... | 10 | 129 |
| प्रजापतिः वाच्यः | 9 | 84 |
| प्रजापतिः वैश्वामित्रः | 3 | 38, 54 to 56 |
| प्रजावान् प्राजापत्यः ... | 10 | 183 |
| प्रतर्दनः काशिराजः ... | 10 | 179 |
| प्रतर्दनः दैवोदासिः | 9 | 96 |
| प्रतिक्षत्र आत्रेयः | 5 | 46 |
| प्रतिप्रभ आत्रेयः | 5 | 49 |
| प्रतिभानुः आत्रेयः | 5 | 48 |
| प्रतिरथ आत्रेयः... | 5 | 47 |
| प्रथः वासिष्ठः ... | 10 | 181 |
| प्रभूवसुः .. | 9 | 35, 36 |
| प्रभूवसुः आङ्गिरसः | 5 | 35, 36 |
| प्रयस्वन्तः आत्रेयः | 5 | 20 |
| प्रयोगः भार्गवः ... | 8 | 102 |
| प्रस्कण्वः ... | 9 | 95 |
| प्रस्कण्वः काण्वः | 1 | 44 to 50 |
| प्रस्कण्वः (काण्व ) | 8 | 49 |
| प्राजापत्यो वाग्नुक्रः | 10 | 20 to 26 |
| प्रियमेधः ... | 8 | 68, 69 |
| | 9 | 28 |

| | म. | सू. |
|---|---|---|
| प्रियमेधः आङ्गिरसः ... | 8 | 2 |
| प्रियमेधः वासिष्ठः | 8 | 87 |
| बन्धुः गोपायनः... | 10 | 57 to 60 |
| बन्धुः गोपायनो लोपायनो वा | 5 | 24 |
| बभ्रुः आत्रेयः .. | 5 | 30 |
| बरुः ... ... | 10 | 96 |
| बाहुवृक्तः आत्रेयः | 5 | 71, 72 |
| बिन्दुः ... ... | 9 | 30 |
| | 8 | 94 |
| बुधः आत्रेयः ... | 5 | 1 |
| बुधः सौम्यः ... | 10 | 101 |
| बृहदुक्थो वामदेव्यः .. | 10 | 54 to 56 |
| बृहद्दिवः आथर्वणः | 10 | 120 |
| बृहन्मतिः ... | 9 | 39, 40 |
| बृहस्पतिः ... | 10 | 71 72 |
| बृहस्पतिः लौक्यः | 10 | 72 |
| ब्रह्मातिथिः काण्वः | 8 | 5 |
| भयमानः वार्षगिरः राजर्षिः ... | 1 | 100 |
| भरद्वाजः ... | 9 | 67 |
| भरद्वाजः बार्हस्पत्यः ... | 6 | 1 to 30 37 to 43, 53 to 74 |
| भर्गः प्रागाथः ... | 8 | 60, 61 |
| भावयव्यः ... | 1 | 126 |
| भिक्षुः | 10 | 117 |
| भिषक् आथर्वणः | 10 | 97 |
| भुवनः (आप्त्यः) | 10 | 157 |
| भूतांशः काश्यपः | 10 | 106 |
| भृगुः वारुणिः ... | 9 | 65 |
| | 10 | 19 |
| मत्स्यः (मान्यः)... | 8 | 67 |
| मत्स्यः सामदः ... | 8 | 67 |
| मत्स्याः जालनद्धाः ... | 8 | 67 |
| मथितः यामायनः | 10 | 19 |
| मधुच्छन्दाः वैश्वामित्रः .. | 1 | 1 to 10 |
| मधुच्छन्दाः ... | 9 | 1 |
| मनुराप्सवः ... | 9 | 106 |
| मनुः (वैवस्वतः)... | 8 | 27 to 31 |
| मनुः सांवरणः .. | 9 | 101 |

| | म. | सू. |
|---|---|---|
| मन्युः तापसः ... | 10 | 83, 84 |
| मन्युः वासिष्ठः ... | 9 | 97 |
| मरुतः ... | 1 | 165, |
| | 1 | 171 |
| मातरिश्वा (काण्वः) | 8 | 54 |
| मान्धाता यौवनाश्वः ... | 10 | 134 |
| मुद्गलः भार्म्यश्वः... | 10 | 102 |
| मुनयः वातरशनाः | 10 | 136 |
| मूर्धन्वान् आङ्गिरसो वामदेव्यो-वा ... | 10 | 88 |
| मृळीकः वासिष्ठः... | 9 | 97 |
| | 10 | 150 |
| मेधातिथिः ... | 8 | 2 |
| | 9 | 2 |
| मेधातिथिः काण्वः ... | 1 | 12 to 23 |
| | 8 | 1, 2, 32 |
| मेध्यः काण्वः ... | 8 | 53,57, 68 |
| मेध्यातिथिः ... | 9 | 41 to 43 |
| मेध्यातिथिः काण्वः | 8 | 1, 3, 33 |
| मैत्रावरुणिः | 8 | 67 |
| यक्ष्मनाशनः प्राजापत्यः ... | 10 | 161 |
| यजत आत्रेयः ... | 5 | 67, 68 |
| यज्ञः प्राजापत्यः... | 10 | 130 |
| यमः ... | 10 | 14 |
| यमो वैवस्वतः .. | 10 | 10 |
| यमी ... | 10 | 154 |
| यमी वैवस्वती ... | 10 | 10 |
| ययातिर्नाहुषः ... | 9 | 101 |
| यविष्ठाग्निः सहसः सुतः .. | 8 | 102 |
| रक्षोहा ब्राह्मः ... | 10 | 162 |
| रहूगणः ... | 9 | 37, 38 |
| रातहव्यः आत्रेयः | 5 | 65, 66 |
| रात्रिः भारद्वाजी | 10 | 127 |
| रामः जमदग्निसुतः | 10 | 110 |
| रेणुः ... | 10 | 89 |
| रेणुः वैश्वामित्रः ... | 9 | 70 |
| रेभः काश्यपः ... | 8 | 97 |
| रेभसूनू काश्यपौ... | 9 | 99, 100 |

| | म. | सू. |
|---|---|---|
| रोमशा .. ... | 1 | 126 |
| लबः ऐन्द्रः ... | 10 | 119 |
| लुशः धानाकः ... | 10 | 35, 36 |
| लोपामुद्रा ... | 1 | 179 |
| वज्राश्वः वार्षागिरः (राजर्षिः) ... | 1 | 100 |
| वत्सः काण्वः ... | 8 | 6, 11 |
| वत्सः आग्नेयः ... | 10 | 187 |
| वत्सप्रिः ... | 10 | 45, 46 |
| वत्सप्रिः भालन्दनः | 9 | 68 |
| वम्रः वैखानसः ... | 10 | 99 |
| वव्रिः आत्रेयः ... | 5 | 19 |
| वशः अश्व्यः ... | 8 | 46 |
| वसिष्ठः ... | 7 | 1 to 104 |
| वसिष्ठः ... | 9 | 67, 90, 97 |
| वसिष्ठपुत्राः ... | 7 | 33 |
| वसुः भारद्वाजः ... | 9 | 80, 82 |
| वसुकर्णः वासुक्रः | 10 | 65, 66 |
| वसुकृद् वासुक्रः | 10 | 20, to 26 |
| वसुक्रः ... | 10 | 29 |
| वसुक्रः ऐन्द्रः ... | 10 | 27, 28 |

| | म. | सू. |
|---|---|---|
| वसुक्रः वासिष्ठः... | 9 | 97 |
| वसुरोचिषः आङ्गिरसः सहस्रं... | 8 | 34 |
| वसुश्रुतः आत्रेयः | 5 | 3 to 6 |
| वसुमना रौहिदश्वः | 10 | 179 |
| वसूयवः आत्रेयाः | 5 | 25, 26 |
| वागांभृणी ... | 10 | 125 |
| वाच्यः ... | 3 | 38, 54 to 56 |
| वामदेवः ... | 4 | 1 to 41, 45 to 58 |
| विप्रबन्धुः गोपायनः ... | 10 | 57 to 60 |
| विप्रबन्धुः गोपायनः लोपायनो वा | 5 | 24 |
| विभ्राट् सौर्यः ... | 10 | 170 |
| विमदः ऐन्द्रः ... | 10 | 20 to 26 |
| विरूपः ... | 8 | 75 |
| विरूपः आङ्गिरसः | 8 | 43, 44 |
| विवस्वान् आदित्यः | 10 | 13 |
| विवृहाः काश्यपः | 10 | 163 |

| | म | सू. |
|---|---|---|
| विश्वकः कार्ष्णिः | 8 | 86 |
| विश्वकर्मा भौवनः | 10 | 81, 82 |
| विश्वमना वैयश्वः | 8 | 23 to 26 |
| विश्ववारात्रेयी ... | 5 | 28 |
| विश्वसामात्रेयः ... | 5 | 22 |
| विश्वामित्रः ... | 3 | 2 to 12, 24 to 53 57 to 62 |
| | 9 | 67 |
| | 10 | 167 |
| विश्वामित्रः गाथिनः | 3 | 1 |
| विश्वावसुः देवगन्धर्वः ... | 10 | 139 |
| विष्णुः प्राजापत्यः | 10 | 184 |
| विहव्यः ... | 10 | 128 |
| वीतहव्यः ... | 6 | 15 |
| वृशः जारः ... | 5 | 2 |
| वृषाकपिरैन्द्रः ... | 10 | 86 |
| वृषगणो वासिष्ठः | 9 | 97 |
| वेनः ... | 10 | 123 |
| वेनः भार्गवः ... | 9 | 85 |
| वैखानसाः शतम् | 9 | 66 |

| | म. | सू. |
|---|---|---|
| वैश्वानरः ... | 10 | 79, 80 |
| व्यश्वः आङ्गिरसः | 8 | 26 |
| व्याघ्रपाद्वासिष्ठः | 9 | 97 |
| शंयुः बार्हस्पत्यः... | 6 | 44 to 46, 48 |
| शकपूतः नार्मेधः | 10 | 132 |
| शक्तिः ... ... | 7 | 32 |
| | 9 | 108 |
| शक्तिवासिष्ठः ... | 9 | 97 |
| शङ्खो यामायनः... | 10 | 15 |
| शची पौलोमी ... | 10 | 159 |
| शतप्रभेदनो वैरूपः | 10 | 113 |
| शबरः काक्षीवतः | 10 | 169 |
| शार्यातो मानवः | 10 | 92 |
| शशकर्णः काण्वः | 8 | 9 |
| शश्वती आङ्गिरसी आसङ्गस्य पत्नी | 8 | 1 |
| शार्ङ्गाः ... | 10 | 142 |
| शासः भरद्वाजः... | 10 | 152 |
| शिखण्डिन्यौ काश्यप्यौ अप्सरसौ ... | 9 | 104 |
| शिबिरौशीनरः ... | 10 | 179 |
| शिरिंबिठः भारद्वाजः ... | 10 | 155 |

| | म | सू |
|---|---|---|
| शिशुः .. ... | 9 | 112 |
| शुनश्शेफः ... | 9 | 3 |
| शुनश्शेफः आजीगर्तिः ... | 1 | 24 to 30 |
| शुनहोत्रः ... | 6 | 33, 34 |
| श्यावाश्वः ... | 8 | 35 to 38 |
| | 9 | 32 |
| श्यावाश्वः आत्रेयः | 5 | 52 to 61, 81 82 |
| श्येनः आग्नेयः ... | 10 | 188 |
| श्रद्धा कामायनी | 10 | 151 |
| श्रुतकक्षः ... | 8 | 92 |
| श्रुतबन्धुः गोपायनः | 10 | 57 to 60 |
| श्रुतबन्धुः गोपायनः लोपायनो वा | 5 | 24 |
| श्रुतविदात्रेयः ... | 5 | 62 |
| श्रुष्टिगुः काण्वः... | 8 | 51 |
| सङ्कुमुकः यामायनः | 10 | 18 |
| संवननः ... | 10 | 191 |
| संवरणः प्राजापत्यः | 5 | 33, 34 |
| संवर्तः ... | 10 | 172 |

| | म. | सू. |
|---|---|---|
| सत्यधृतिः वारुणिः | 10 | 185 |
| सत्यश्रवा आत्रेयः | 5 | 79, 80 |
| सदापृणः आत्रेयः | 5 | 45 |
| सध्रिः वैरूपः ... | 10 | 114 |
| सध्वंसः काण्वः ... | 8 | 8 |
| सप्तगुः ... | 10 | 47 |
| सप्तर्षयः ... | 9 | 107 |
| सप्तर्षयः एकर्चाः... | 10 | 137 |
| सप्तवध्रिः ... | 8 | 73 |
| सप्तवध्रिरात्रेयः .. | 5 | 78 |
| सप्तिः वाजम्भरः... | 10 | 79 |
| सप्रथो भारद्वाजः | 10 | 181 |
| सरमा देवशुनी ... | 10 | 108 |
| सर्वहरिः ऐन्द्रः ... | 10 | 96 |
| सव्यः आङ्गिरसः | 1 | 51 to 57 |
| ससः आत्रेयः ... | 5 | 21 |
| सहदेवः वार्षागिरः | 1 | 100 |
| साधनः भौवनः ... | 10 | 157 |
| सार्पराज्ञी ... | 10 | 189 |
| सिकतानिवावरी | 9 | 86 |
| सिन्धुक्षित् प्रैयमेधः | 10 | 75 |
| सिन्धुद्वीपः अम्बरीषः ... | 10 | 9 |
| सुकक्षः... ... | 8 | 92, 93 |

| | म. | सू. |
|---|---|---|
| सुकीर्तिः काक्षीवतः | 10 | 131 |
| सुतम्भरः आत्रेयः | 5 | 11 to 14 |
| सुदाः पैजवनः ... | 10 | 133 |
| सुदीतिः ... | 8 | 71 |
| सुपर्णः काण्वः ... | 8 | 59 |
| सुपर्णः तार्क्ष्यपुत्रः | 10 | 144 |
| सुबन्धुः गोपायनः लोपायनो वा | 5 | 24 |
| सुबन्धुः गोपायनः | 10 | 57 to 60 |
| सुमित्रः वाध्र्यश्वः | 10 | 69, 70 |
| सुमित्रः कौत्सः दुर्मित्रः ... | 10 | 105 |
| सुराधसः वार्षागिरः राजर्षिः ... | 1 | 100 |
| सुवेदाः शैरीषिः... | 10 | 147 |
| सुहस्त्यः घौषेयः | 10 | 41 |
| सुहोत्रः ... | 6 | 31, 32 |
| सूनुः आर्भवः ... | 10 | 176 |
| सूर्या सावित्री ... | 10 | 85 |
| सोमाहुतिः भार्गवः | 2 | 4 to 7 |
| सौभरिः काण्वः ... | 8 | 19 to 22, 103 |
| स्यूमरश्मिः भार्गवः | 10 | 77, 78 |
| स्वस्त्यात्रेयः .. | 5 | 50, 51 |
| हर्यतः प्रागाथः ... | 8 | 72 |
| हरिमन्तः ... | 9 | 72 |
| हविर्धानः आङ्गिः | 10 | 11, 12 |
| हिरण्यगर्भः प्राजापत्यः ... | 10 | 121 |
| हिरण्यस्तूपः ... | 9 | 4, 69 |
| हिरण्यस्तूपः आङ्गिरसः ... | 1 | 31 to 35 |

The following table, prepared from a printed text of the Rg-vēda, shows the number of Sūktas and Rcas in each Mandala and the number of Vargas and Rcas in each Astaka of the Rgvēda —

| मण्डलम् | सूक्तम् | ऋक् | अष्टकम् | वर्गः | ऋक् |
|---|---|---|---|---|---|
| I | 191 | 1,986 | I | 265 | 1,350 |
| II | 43 | 429 | II | 221 | 1,147 |
| III | 62 | 617 | III | 225 | 1,209 |
| IV | 58 | 589 | IV | 250 | 1,288 |
| V | 87 | 726 | V | 238 | 1,263 |
| VI | 75 | 765 | VI | 331 | 1,730 |
| VII | 104 | 841 | VII | 248 | 1,263 |
| VIII | 103 | 1,716 | VIII | 246 | 1,281 |
| IX | 114 | 1,108 | | | |
| X | 191 | 1,754 | | | |
| | 1,028 | 10,531 | | 2,024 | 10,531 |

The following shows the relation of Astaka to Mandala :—

| अष्टकम् | From | | To | |
|---|---|---|---|---|
| | म. | सू. | म. | सू. |
| I | i | 1 | i | 121 |
| II | i | 122 | iii | 6 |
| III | iii | 7 | v | 8 |
| IV | v | 9 | vi | 61 |
| V | vi | 62 | viii | 11 |
| VI | viii | 12 | ix | 43 |
| VII | ix | 44 | x | 45 |
| VIII | x | 46 | x | 191 |

## No 8 ऋग्वेदपदपाठः.

## RGVĒDAPADAPĀTHAH

Substance, paper Size, 13 × 8 inches Pages, 956. Lines, 27 on a page Character, Telugu Appearance, old In good condition.

Contains the Padapātha of the eight Astakas complete.

The Padapātha is a particular mode of reciting the Rgvēda Samhitā, in which each word is uttered separately and without the euphonic changes in the forms and the svaras of the words

A sage named Śākalya is said to have been the author of the Padapātha of the Rgvēda.

**Beginning:**

हरिःओं ॥ अग्निं । ईळे । पुरः हितं । यज्ञस्य । देवं । ऋत्विजं । होतारं । रत्न धातमम् ॥

**End:**

समानी । वः । आ कूतिः । समाना । हृदयानि । वः ॥ समानम् । अस्तु । वः । मनः । यथा । वः । सु सह । असति ॥ हरिः ओं ॥

---

## No 9. ऋग्वेदपदपाठः.

## RGVĒDAPADAPĀTHAH

Substance, palm-leaf (śrītāla) Size, 16 × 1¾ inches Pages, 460 Lines, 8 on a page. Character, Malayālam Appearance, new. In excellent order Begins with folio, 2.

Contains the first four Astakas complete Accented

The very first folio contains the following written in ink:—

"Vol I This volume contains the 1st, 2nd, 3rd and 4th Astakas of the Samhita of the Rigvēdam, Malayālam, *Ārya* character.

CALICUT, *January* 1825. C. W. WHISH."

The last folio contains the following·—

"This volume contains the 1st, 2nd, 3rd and 4th Aṣṭakas of the Samhita of the Rigvēdah

Here ends the first volume of the Rigvēdam. *Ārya* character

CALICUT, 1825. C W WHISH."

*Memorandum*

"The Gāyatri in this copy is found in the last line of the first side of the **1**46th page

CALICUT, 1825. C W WHISH"

The perpendicular stroke stands for the Udātta in this and the following manuscripts except in Nos 12 and 15.

**Beginning:**

अग्नि । ईळे । पुरः हितं । यज्ञस्य । देवं । ऋत्विजं । होतारं । रत्न धातमम् ।

**End:**

सरस्वति । अभि । नः । नेषि । वस्यः । मा । अप । स्फरीः पयसा । मा । नः । आ । धक् । जुषस्व । नः । सख्या । वेश्या । च । मा । त्वत् ।क्षेत्राणि । अरणानि । गन्म ॥

**Colophon:**—इति चतुर्थाष्टकेऽष्टमोऽध्यायः ॥

---

## No 10. ऋग्वेदपदपाठः.

## ṚGVĒDAPADAPĀTHAḤ

Substance, palm-leaf (śrītāḷa) Size, 17 × $1\frac{3}{4}$ inches. Character, Malayālam. Pages, 336. Lines, 9 on a page Appearance, new. In excellent order.

Contains Aṣṭakas 5—8 complete.

Accented Begins on folio 2. The upper stroke stands for the Udātta.

This also belongs to the Calicut series of C W WHISH and contains the following note :—

"Vol. II This volume contains the 5th, 6th, 7th and 8th Astakas of the *Samhita* (Pada text) of the Rigvēdah *Ārya* character.

CALICUT, 1825 C W WHISH

" This volume contains the 5th, 6th, 7th and 8th Aṣṭakas of the Samhita of the Rigvēdah.

Here ends the second volume of the Rigvēdah.

CALICUT, 1825. C W WHISH"

**Beginning:**

स्तुषे । नरा । दिवः । अस्य । प्रसन्ता । आश्विना । हुवे । जरमाणः अर्कैः ॥ या । सद्यः । उस्रा । वि उषि । ज्मः । अन्तान् । युयूषतः । परि । उरु । वरांसि ॥

**End:**

समानी । वः । आ कूतिः । समाना । हृदयानि । वः । समानं । अस्तु । वः । मनः । यथा । वः । सु सह । असति ॥

**Colophon:**—इत्यष्टमेऽष्टकेऽष्टमोऽध्यायः ॥

---

## No 11. ऋग्वेदपदपाठः.

## ṚGVĒDAPADAPĀTHAH.

Substance, palm-leaf (śrītāla). Size, 17½ × 1¾ inches. Pages, 450. Lines, 9 on a page. Character, Grantha. Appearance, more than 60 years old. Slightly injured.

Contains the Padapāṭha of Aṣṭakas 5–8 complete.

Accented. The upper stroke stands for the Udātta.

This belongs to the Calicut series and contains the following note :—

"The Samhita of the Rigvēdah In three volumes Grantha character.

CALICUT, January 1825. C W WHISH."

"Vol III Rigvēdah This volume contains the 5th, 6th, 7th and 8th Astakas of the Rigvēdah Here ends Vol III of the Rigvēdah

"This volume contains the 5th, 6th, 7th and 8th Astakas of the Samhita of the Rigvēdah complete in thirty-two Adhyayas

CALICUT, 1825 C W WHISH"

"Here ends the Rigvēdam complete in eight Astakas In three volumes Grantham character

CALICUT, 1825. C W WHISH."

For beginning and end see the previous notice

---

## No 12. ऋग्वेदपदपाठः
## RGVĒDAPADAPĀTHAH.

Substance, palm-leaf Size, 15¼ × 1½ inches Pages, 294. Lines, 7 on a page Character, Telugu Appearance, new. Very injured.

Contains the whole of Astaka 1, and the Astaka 8, from the beginning to the 41st Varga of the 8th Adhyāya. About 15 folios in the beginning are accented.

**Beginning** of Astaka I :

अग्निं । ईळे । पुरः हितं । यज्ञस्यं । देवं । ऋत्विजं । होतारं । रत्न धातमम् ॥

**End:**

मा । सा । ते । अस्मत् । सु मतिः । वि दसत् । वाज प्र महः । सम् । इषः । वरन्त । आ । नः । भज । मघ वन् । गोषु । अ ीः । मंहिष्ठाः । ते । सध मादः । स्याम । हरिः ओं ॥

**Beginning** of Astaka VIII:

प्र । हेता । जातः । महान् । नभः विन् । नृ सद्मा । सीदत् । अपां । उपस्थे ॥ दाधिः । यः । दापि । सः । ते । वयांसि । यन्ता । वसूनि । विधते । तनूपाः ॥

**End:**

अहं । गर्भं । अदधां । ओषधीषु । अहं । विश्वेषु । भुवनेषु । अन्तरिति । अहं । प्रजाः । अजनयं । पृथिव्यां । अहं । जनि भ्यः । अपरीषु । पुत्रान् ॥ 41 ॥

---

## No 13 ऋग्वदपदपाठः.

## RGVĒDAPADAPĀTHAH

Substance, (Srītāla) palm-leaf Size, 15½ × 1½ inches. Pages, 158. Lines, 7 on a page Character, Grantha Appearance, new In very good order.

Contains the Padapātha of the 1st Astaka complete

Accented The upper stroke stands for the Udātta

"Vol. I. This volume contains the first Astaka of the Rigvēdah. Vol. I Rigvēdah.

CALICUT, 1825. C. W WHISH"

"This volume contains the first Astaka of the Rigvēdah complete in 8 Adhyāyas.

CALICUT, 1828. C. W WHISH"

**Beginning:**

अग्निं । ईळे । पुरः हितं । यज्ञस्य । देवं । ऋत्विजं । होतारं । रत्न धातमन् ।

**End:**

मा । सा । ते । व्य । अस्मत् । सु मतिः । वि । दसत् । वाज प्रमहः । सं । इषः । वरंत । आ । नः । भज । मघ वन् । गोषु । अर्यः । मंहिष्ठाः । ते । सध मादः । स्याम ॥ 26 ॥

**Colophon:**—इति प्रथमेऽष्टकेऽष्टमोऽध्यायः ॥

---

No **14.** ऋग्वेदपदपाठः.

RGVĒDAPADAPĀTHAH

Substance, palm-leaf Size, 18 × 1¾ inches. Pages, 70. Lines, 9 on a page Character, Telugu Imperfect and incomplete. In good condition

The opening leaf is numbered 29 and the last one 105; and many leaves are wanting in the middle

The manuscript begins in the middle of the 14th Varga of the 5th Adhyāya of the 1st Astaka and ends with the 8th Adhyāya of the 2nd Astaka

On account of its imperfection no extract is given.

---

No. **15.** ऋग्वेदपदपाठः.

RGVĒDAPADAPĀṬHAH

Substance, palm-leaf Size, 14½ × 1¼ inches Pages, 332 Lines, 6 on a page Character, Telugu. In good order. Appearance, new.

Contains the 7th and 8th Adhyāyas of the 6th Astaka, the 7th and 8th Astakas, and the 1st Adhyāya of the 5th Astaka.

The following other works also are contained in this manuscript; Rgvēda Padasankhyā (fol. 167); Chandōnirnaya (fol. 193); Agnihōtraprayōga (fol. 198) :—

**Beginning:**

हरिः ओं ॥ इन्द्राय । साम । गायत । विप्राय । बृहते । बृहत् । धर्म कृते । विपः चिते । पनस्यवे ।

**End:**

नु । मे । ब्रह्मणि । अग्ने । उत् । शशाधि । त्वं । देव । मघवत्भ्यः । सुसूदः ॥ रातौ । स्याम । उभयासः । आ । ते । यूयं । पात । स्वस्ति- भिः । सदा । नः

---

## No. 16. ऋग्वेदभाष्यम् (वेदार्थप्रकाशः).

## ṚGVĒDABHĀṢYAM (VĒDĀRTHAPRAKASAH).

Substance, palm-leaf Size, 15½ × 1½ inches. Pages, 130 Lines, 8 on a page. Character, Grantha. Appearance, old. Injured

Incomplete. The well-known commentary by Sāyanācārya, the prime minister of Vīrabukka, the king of Vijayanagaram

The commentary of the whole samhita of the Ṛgvēda has been edited by Professor Max Muller; and the first chapter alone by Dr. Roer in the Bibl Indica The first three Adhyāyas only have been commented upon by Ānandatīrtha in such a way that each Ṛk is made to refer to god Visnu, and that the name of every other deity indicates that deity alone. Some say that Ānandatīrtha wrote a commentary on the whole of the Samhitā, but this opinion is opposed to the statement of Jayatīrtha, who wrote a gloss on the Bhāṣya of Ānandatīrtha and says 'कासांचन ऋचां भाष्यं करिष्यन्नाचार्यः' "the teacher going to comment upon a few rcas"

One hundred and forty leaves in the beginning being lost, the manuscript begins from the 4th Ṛk of the 34th Varga of the 1st Adhyāya in the 1st Astaka, and ends with the 4th Ṛk of the 38th Varga of the 2nd Adhyāya in the same Astaka

**Beginning:**

* * * *

(ब्रह्म)णस्पतिर्देवो हिनोति । तथा सोमो हिनोति । स घा स एव यजमानः । वीरो वीर्ययुक्तस्सन् न रिष्यति न विनश्यति । (घा) चादिरनु-

दात्तः। संहितायां "ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्" इति दीर्घः। ब्रह्मण-स्पतिः। उक्तं। हिनोति। हिगतौ वृद्धौ च। स्वादिभ्यः श्नुः। तिपः पित्वात श्नुप्रत्ययस्वर एव विशिष्यते। द्रुदक्षिभ्यामिनन्।

पञ्चमीमृचमाह।

त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम्। दक्षिणा पात्वंहसः।

हे ब्रह्मणस्पते सोम त्वं तं मर्त्यं अनुष्ठातारं मनुष्यं अंहसः पापात पाहीति शेषः॥

इति प्रथमस्य प्रथमे चतुस्त्रिंशो वर्गः.

* * *

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋग्वेदसंहितायां प्रथमाष्टके प्रथमोऽध्यायः॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥

अथ प्रथमाष्टके द्वितियाध्याय आरभ्यते॥

**End:**

अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत्। नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि।

हे इन्द्र वृत्रं जघ्नुषो वृत्रं हतवतस्तव हृदि चित्ते यत्ते यत् यदि भीरगच्छत् (न) हतवानस्मीति बुद्ध्या भयं प्राप्नुयात्। तर्हि अहेर्वृत्रस्य यातारं हन्तारं कमपश्यः त्वत्तोऽन्यं कं पुरुषं दृष्टवानसि। तादृशस्य पुरुषान्तरस्या-

भावान्मा भूत्तव भयमित्यर्थः । यद्यस्मात् नव च नवतिं च स्रवन्तीः एकोनशतसङ्ख्याकाः प्रवहन्तीर्नदीः प्राप्य रजांसि तत्रत्यान्युदकान्यतरः तीर्णवानसि । तव दृष्टान्तः । श्येनो न । श्येननामको बलवान् पक्षीव दूरगमनात्तव भयमासीदिति गम्यते । तद्भयं मा भूदित्यभिप्रायः । तच्च दूरगमनं ब्राह्मणे समाम्नातम् ।

---

## No 17. श्रीसूक्तम्
## ŚRĪSŪKTAM

Substance, palm-leaf Size, 7½ × 1½ inches. Begins on folio 10*a*. Pages, 8 Lines, 5 on a page. Character, Telugu Appearance, old. In good order

Contains the whole of the work named.

The name Śrīsūkta is applied to a collection of hymns occurring in the Ṛgvēda and dedicated to Śrī, the Goddess of Fortune. It is one of the thousand Sūktās belonging to the Ṛgvēda It is placed at the end of the fifth Mandala and is printed in the Preface to Ṛgvēda, Vol III, by Professor Max Muller, with some additional verses addressed to gods Siva and Visnu, at the end of which comes the following line: एतान्यनन्तनामानि मण्डलान्ते सदा जपेत् ॥ The Śrīsūkta is referred to in the Bōdhāyana's Gṛhya in the following passage: हिरण्यवर्णां हरिणीमिति पञ्चदशर्चं श्रीसूक्तम् ।

The Śrīsūkta is recited by the Brāhmans belonging to the Sāma Vēda also. But there is a separate Sūkta among them, the text of which is entirely different and is mentioned in the following passage under the same name —

श्रीसूक्तं घृतसूक्तं च भूसूक्तं पुरुषसूक्तकम् ।
वारुणं पञ्चशान्तिश्च ब्राह्मं रौद्रञ्च सूक्तकम् ॥

20th Khanda, Gautamagṛhyapariśiṣṭa.

श्रीसूक्तस्य विवरणम् ॥ गावश्चिद्वासां मन्यवः । यद्यावं अष्टसामानि सखाय आ पञ्चसामानि ॥

The second passage, quoted above from a work on the household ritual of the Sāmavēdi Brāhmans, explains what is meant by Śrīsūkta, mentioning the three hymns which are collectively known as Śrīsūkta, viz ,

गावश्चिद्वासांमन्यवः Prap. V. 1, 2.

यद्याव, &c , eight hymns Prap. III 2, 4.

सखाय आ, &c , five hymns Prap VI 2, 3.

The Śrīsūkta is also used by the Brāhmans who belong to the Atharva Vēda as can be seen from the following passage :—

नन्वथर्वसंहितायां श्रीसूक्तादर्शनात् श्रीसूक्तमाथर्वणं नास्तीति चेन्न सप्तशतीव्याख्यादिषु श्रीसूक्तमाथर्वणमिति शिष्टोक्तेः उच्छिन्नशाखासु तत्कल्पनस्यैवौचित्यात् ॥

The Śrīsūkta is referred to in the Visṇu Purāṇa, the first book, ninth chapter :—

ततः स्फुरत्कान्तिमति विकासिकमले स्थिता ।
श्रीर्देवी पयसस्तस्मादुत्थिता धृतपङ्कजा ।
तां तुष्टुवुर्मुदा युक्ताः श्रीसूक्तेन महर्षयः ।

The other works found in this MS. are Purusasūktam (fol. 1*a*), Daśaśāntih (fol. 6*a*), . . Namakam (fol 14*a*), Pāśupatāstram (fol 18*a*), Dēvīstavaḥ (fol 22*a*), Sivōmēgāyatryasṭakam (fol. 24*a*), Ēkāmrēśvarāstakam (fol 26*a*), Śivastutih (fol 28*a*), Chāyāpurusalaksanam (fol. 32*a*), Ṣaḍvarṇamantrāstakam (fol. 35*a*).

**Beginning:**

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह॥

**End:**

ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥

(आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः)
ऋषयस्ते त्रयः पुत्राः स्वयं श्रीरेव देवता ।
पद्मानने पद्मोरु पद्माक्षि पद्मसम्भवे ।
त्वं मां भजस्व पद्माक्षि येन सौख्यं लभाम्यहम् ॥

* * *

सिद्धलक्ष्मीर्मोक्षलक्ष्मीः जयलक्ष्मीः सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां जगदीश्वरीं ताम् ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् ।

श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥

महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥
ओं शान्तिः शान्तिः शान्तिः ।



## No 18. श्रीसूक्तम्.
## ŚRĪSŪKTAM.

Substance, palm-leaf Size, 11 × 1¼ inches. Begins with folio 37*a*. Pages, 7 Lines, 4 on a page. Character, Nandināgarī. Appearance, old. Injured.

Complete The same as the above

The following are the names of other works contained in this codex · Vighnēśvaradvādaśanāmastōtram (fol 1*a*), Vināyakāstōttaraśatam (fol 2*a*), Gangādharavicārah savyākhyah (fol 8*a*), Nānāvidhavisayah (miscellaneous matters) (fol 16*a*), Pārthivaliṅgapūjāvidhih (fol. 26*a*), . . . Nārāyanasūktam (fol 40*a*), Krsnayajus, Astka 1 (fol. 42*a*), Navagrahaśāntih (fol. 44*b*), Jayādihōmaprayōgah (fol 51*a*)

**Beginning:**

हिरण्यवर्णां . . . . . . . ममावह ॥

**End:**

ताम्म आवह . . . . नहम् ॥

* * *

सर्वमङ्गलमाङ्गल्ये . . . . . नमोऽस्तु ते ॥

आभिर्गीर्भिर्यद्‌तो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रारुजासि भूयिष्ठभाजो अथ ते स्याम॥ ब्रह्म प्रावादिष्म तं नो मा हासीत्। ओं शान्तिः शान्तिः शान्तिः ॥

---

## No 19. श्रीसूक्तम्.
## ŚRĪSŪKTAM.

Substance, palm-leaf Size, 12¾ × 1 inches Pages, 6 Lines, 6 on a page. Character, Grantha. Appearance, old. Injured.

Complete. The same as the above.

This codex contains also the Varuṇasūktam (fol. 4*a*) and the Aghamarsaṇasūktam (fol 5*a*)

**Beginning:**

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । . . . . अवतु वक्तारं । ओं शान्तिः शान्तिः शान्तिः । शं नो मित्रः शं वरुणः । . . . . . . आवीद्वक्तारं । ओं शान्तिः शान्तिः शान्तिः ॥

हिरण्यवर्णां हरिणीं . . . . . ।
. . . . . . . ममावह ॥

**End:**

ताम्म आवह . . . . . नहम् ॥

श्रिये जातश्रिय आनिर्याय श्रियंवदो जनितृभ्यो दधातु ।
श्रियं वसाना अमृतत्वमायन् ।
भवन्ति सद्यस्समिधामि दध्यून् ॥

श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्य सन्धत्तं सन्धीयते प्रजया पशुभिः । य एवं वेद । ओं महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥

---

No. **20.** श्रीसूक्तम्.
ŚRĪSŪKTAM.

Substance, palm-leaf Size, 15¾ × 1 inches Begins on folio 4*b*. Pages, 3 Lines, 5 on a page Character, Grantha Appearance, new Injured

Complete. The same as the above.

Puruṣasūktam (fol 1*a*), . . . Bhūsūktam (fol 5*b*), and Abhiśravaṇam (fol. 7*a*), are also found in this codex.

**Beginning:**

हिरण्यवर्णां . . . ममावह ॥

**End:**

ताम्म आवह . . . पुरुषानहम् ॥

श्रिय . . . . . . प्रचोदयात् ॥

---

## No 21. श्रीसूक्तम्.
## ŚRĪSŪKTAM

Substance, palm-leaf Size, 12½ × 1¼ inches Begins on folio 79*a*. Pages, 6 Lines, 7 on a page Character, Telugu Appearance, old In good order

Complete

The same as the above to be recited in the form of a Mantra with additional matters

The following is a list of other works contained in this MS :—

| | Begins on folio |
|---|---|
| Śābaramantrālu .. | 1*a* |
| Śūnyamcampumantramu | 1*a* |
| Śābarmantrālu .. .. | 2*a* |
| Hiranyadēvīsūktam .. | 4*a* |
| Srīsūktōddhāraḥ .. | 5*a* |
| Pratyaṅgirāmahālaksmīmantrah .. .. | 16*a* |
| Pratyaṅgirāmālāmantrah | 25*a* |
| Pratyaṅgirāvyākhyānam | 25*b* |
| Pratyangirāmahāyantrakalpah .. .. | 27*b* |
| Pratyaṅgirāmālā .. | 30*a* |
| Rudrāstōttaraśatanāmāvalih .. .. .. | 31*a* |
| Pāśupatāstram .. .. | 32*a* |
| Vanadurgāmahālaksmīmantrah .. .. | 37*a* |
| Rāksasadigbandhah .. | 40*a* |
| Grahanirnayamu .. | 44*a* |
| Dēvatāgrahalaksaṇamu. | 44*a* |
| Daityagrahalaksanamu. . | 44*a* |
| Gandharvagrahalaksanamu .. .. .. | 44*a* |
| Uragagrahalaksaṇamu .. | 44*b* |
| Yaksagrahalaksaṇamu .. | 44*b* |
| Brahmarākṣasagrahalaksanamu .. .. | 44*b* |
| Rāksasagrahalaksanamu. | 44*b* |
| Piśācagrahalaksaṇamu. . | 45*a* |
| Prētagrahalakṣaṇamu .. | 45*a* |

| | Begins on folio |
|---|---|
| Kūśmāṇḍagrahalaksanamu .. .. .. | 45a |
| Kākagrahalaksaṇamu .. | 45a |
| Uragagrahalaksanamu Vētālamunnu .. .. | 45a |
| Asādhyālu .. .. | 45b |
| Bhūtacikitsālu Nasyamulunnu .. .. | 45b |
| Siddhārtaghrtamu .. | 45b |
| Grahanasyāñjanamu .. | 46a |
| Kūrpāsadhūpamu .. | 46a |
| Balidravyālu .. .. | 46a |
| Balisthānālu .. .. | 46a |
| Inguvādighrtamu .. | 46b |
| Gāyatrīghrtamu .. | 46b |
| Śatruvidhvamsinīśūlinī.. | 47a |
| Rājasvajanavaśyamu .. | 47b |
| Vāgbandhanamu .. | 47b |
| Bagalāmukhīpūjāvidhānam .. .. | 48a |
| Śaṅkhārcanam .. .. | 48b |
| Pātrasthāpanam .. | 48b |
| Śukraśāpavimōcanam .. | 49a |
| Ratnapradīpikā .. | 50a |
| Pañcāstrapūjā .. .. | 50b |
| Vighnēśāstakam .. | 50b |
| Angapūjā .. .. | 50b |
| Khadgamālā .. .. | 52a |
| Pādarasaśuddhih (Vaidyacintāmaṇiślōkālu).. | 54a |
| Rasaśuddhiḥ (Telugu) .. | 54b |
| Rasabandhamūlikālu .. | 54b |
| Iṅgilikamainamu .. | 55a |
| Pādarasabandanamantramu .. .. .. | 55a |
| Uttarāyanamantramu .. | 56a |
| Niksēpagrahōccātanamu. | 56a |
| Bagalāmahālaksmīmantrah .. .. | 57a |
| Grahadhūpamu .. .. | 57b |
| Grahāñjanamu .. .. | 57b |
| Pāsānabandhah .. | 58b |
| Rasasahasravēdhah .. | 59a |
| Ucchistaganapatih .. | 60a |
| Rāmasaḍaksarī .. | 63a |
| Rāmakavacah .. .. | 63a |
| Dhūmāvatīkalpah .. | 65a |
| Dhumāvatīmūlamantrah | 65a |
| Dhumāvatīmālāmantrah | 65b |
| Vētālamantrah .. | 66a |
| Añjanam .. .. | 66b |
| Nidhidarśanam .. | 66b |
| Vīrapratāpahanumanmantrah . .. | 67a |
| Vīrapratāpahanumanmālāmantrah.. .. | 67a |
| Hanumatkavacah .. | 67a |
| Kirātavārahīkalpah .. | 69a |
| Dattātrēyasahasranāma | 74a |
| Dattātrēyadvādaśanāmāni .. .. | 78b |
| * * | |
| Śābaramantrah .. .. | 81b |
| Mlōcchagrahah .. .. | 82b |
| Śaktimantrah .. .. | 82b |
| Pāśupatāstram (Sarvaraksā) .. .. | 83a |
| Bhairavōccāṭanam .. | 83b |
| Vighnēsvaramālāmantraḥ .. .. | 84a |

| | Begins on folio |
|---|---|
| Śābarabandhah .. | 84b |
| Rudramantrah .. .. | 84b |
| Śābaramantrah .. .. | 84b |
| Sakalagrahadhūpah .. | 85a |
| Aghōranārasimhōccāṭanam .. .. .. | 86a |
| Ākarsanagrahah .. | 86a |
| Gurunādhunipampu .. | 86b |
| Mullakarigōmantramu .. | 86b |
| Gaḍḍakarigōmantramu .. | 86b |
| Uṅgitimantramu .. | 87a |
| Prasūtigōlēnivārikimantrālu .. .. .. | 87a |
| Canakadurumantrālu .. | 87a |
| Bālagrahalaksanamu .. | 88a |
| Bālaśāstramu .. .. | 90a |
| Bālagrahayantrālu .. | 90a |
| Bālagraharāvaṇīyaśāstramu .. .. | 92a |

**Beginning:**

हिरण्यवर्णामिति पञ्चदशर्चस्य सूक्तस्य मन्त्रस्य आनन्दकर्दमचिक्लीताश्रीसुता ऋषयः । हिरण्यो देवता । आद्यास्तिस्रोऽनुष्टुभः । चतुर्थी बृहती । पञ्चमषष्ठौ त्रिष्टुप् । सप्तम्यष्टम्यावनुष्टुप् । शेषाः प्रस्तारपङ्क्तयः । मम श्रीमहालक्ष्मीप्रसा(दसिद्ध्यर्थे जपे) विनियोगः ॥

ध्यानम् ॥

अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृता पद्मरागैः
सकलभुवनमाता सन्ततं श्रीः श्रियै नः ॥

हिरण्यवर्णां . . . . . . ममावह ॥

**End:**

ताम्म आवह . . . . . . पुरुषानहम् ॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
श्रियः पञ्चदशर्चञ्च श्रीकामः सततं जपेत् ॥

* *

सर्वमङ्गल . . . . . . . नमोऽस्तु ते ॥

लक्ष्मीं . . . . . . . मुकुन्दप्रियाम्.

महादेव्यै च . . . . . . प्रचोदयात्.

सक्तुमिव ततवि (उ) ना पुनन्तो (यत्रधीरा) मनसा वाचमक्रत ।
य (अ) त्रा सखायस्सख्यानि जानत (ते) भद्रैषां लक्ष्मीर्निहिताधि वाचि ।

---

## No. 22. श्रीसूक्तम्.
## ŚRĪSŪKTAM.

Substance, paper Size, 6¾ × 4 inches. Begins on folio 190*a*. Pages, 3. Lines, 24 on a page. Character, Telugu. Appearance, new. In good order.

Complete.

The same as the last with some difference.

This codex contains other works, a list of which is given below:—

| | Begins on folio |
|---|---|
| Bagalā Ekākṣarī .. | 1*a* |
| Bagalāmukhīcaturakṣarī | 1*a* |
| Bagalāṣṭākṣarī .. | 1*b* |
| Bagalāmālā .. .. | 1*b* |
| Bagalāmahālakṣmīmūlam | 2*a* |
| Bagalākavacaḥ .. | 3*a* |
| Bagalāmukhīmantraḥ | 3*b* |
| Bagalānuṣṭhānavidhiḥ | 6*a* |
| Bagalāmukhīmālā .. | 7*a* |
| Navarātrikalpaḥ .. | 8*a* |
| Bagalāpūjā .. .. | 9*b* |
| Bagalānyāsaḥ .. .. | 13*b* |
| Bagalāmukhīvidhānam | 14*b* |
| Bagalāstavaḥ .. .. | 16*a* |
| Bagalāmukhīstōtram .. | 18*a* |
| Bagalāmukhyapūjā .. | 20*a* |
| Bagalāmantraḥ .. | 22*b* |
| Sāṅkhyāyanatantraḥ (Sadvidyāgamaḥ) .. | 25*a* |
| Bhūśuddhiḥ .. .. | 65*a* |
| Svaraśāstrasaṅgrahaḥ .. | 79*a* |
| Svaracintāmaṇiḥ Saṭīkaḥ .. .. | 89*a* |
| Ṛgvēdaprātassandhyāvandanam .. .. | 166*a* |
| Nityārādhanakramaḥ .. | 175*a* |
| * * * | |
| Lakṣmīsahasranāmāvaliḥ .. .. | 193*a* |
| Sītāṣṭottaraśatanāmavaliḥ .. .. | 212*a* |
| Lalitāsahasranāmāvaliḥ. | 214*a* |
| Malayāḷabhagavatī .. | 262*a* |
| Bhadrādrirāmaśatakamu .. .. | 274*a* |

**Beginning:**

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।
नारायणाय ऋषये संशान्ततप ईयुषे ॥

हिरण्यवर्णामिति पञ्चदशर्चस्य सूक्तस्य आनन्दकर्दमचिक्लीता ऋषयः । श्रीर्देवता । श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

हिरण्यवर्णां हरिणीं . . . . . ममावह ॥

**End:**

ताम्म आवह . . . . . पुरुषानहम् ।
श्रिये जात श्रिय . . . . प्रजया पशुभिः ॥

य एवं वेद ॥ ओं महादेव्यै . . . . प्रचोदयात् ॥ यः शुचिः . . . . जपेत् ॥

* * *

सर्वमङ्गल . . . . नमोऽस्तु ते ॥
लक्ष्मीं . . . . . प्रियाम् ॥
सिद्धलक्ष्मीर्मोक्षलक्ष्मीः जयलक्ष्मीः सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां जगदीश्वरीं ताम् ॥

---

## No 23. श्रीसूक्तभाष्यम्.
## ŚRĪSŪKTABHĀṢYAM.

Substance, palm-leaf. Size, 18 × 1½ inches. Begins on folio 198*a*. Pages, 8 Lines, 7 on a page. Character, Telugu. Appearance, new. Injured.

The following other works are found in this codex: Vēdataijasam (Vyāsaśikṣāvyākhyā) (fol. 1*a*), Vyāsaśikṣā (fol 74*a*), Boppana-

bhattīyam (fol 183a), Śrāddhavidhih (fol. 99a), Advaitamakarandah (fol. 118a), Gāyatrīvyākhyā (fol 120b), Visnusahasranāma (fol. 127b), Darśapurnamāsah (fol. 138a), Yājamānam (fol 168a), Āpastambaparibhāsāvyākyā (fol. 170a), Simhānuvākavyākhyānam (fol. 195a), Simhānuvākah (fol 197a),
Parāśarasmrtih (fol. 202a), Gaṇahōmah (fol. 207a), Hanumanmālāmantraḥ (fol 212b).

A commentary ascribed to Vidyādhara, Vidyātīrtha Mahēśvara and Vidyāranyasvāmin and printed by Hall, was reprinted by Max Muller in the Preface to the Rg Vēda, Vol. IV. Verses 11 and 12 of the Śrīsūkta refer to Ciklīta and Kardama respectively, who, according to the commentary, are the sons of the Goddess of Fortune; and a verse which is added at the end of the Śrīsūkta printed in the Preface to the Rg Vēda, Vol. III, by Max Müller mentions Ānanda, a third son of the Goddess.

आनन्दः कर्दमः श्रीदः चिक्लीत इति विश्रुताः ।
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
रोगशोकमनस्तापा नश्यन्तु मम सर्वदा ॥

The first line occurs in the MS. No 22 noticed above, with a slight difference and a new line; and they run as follow :—

आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः ।
ऋषयस्ते त्रयः पुत्राः स्वयं श्रीरेव देवता ॥

From this stanza we learn directly that Ānanda, Kardama and Ciklīta were three sons of the Goddess Laksmī They are also said to be the Rsis to the mantra of the Śrisūkta (p. 41).

It is very curious that Hindu mythology which has been very prolific in every direction has not developed these facts into a long story and has allowed the three names of the sons of Laksmī to remain in oblivion.

The book under notice is a commentary on the Śrīsūkta and seems to have been written by Mādhavācārya from the fact (1) that

it begins with the Ślōka (वेदार्थस्य . . श्वरः) which is generally found in his commentaries, and (2) that it is on comparison identical with the work printed at Madras with Mādhavācāryā's name. But there is no colophon in the manuscript itself to prove the authorship There are many other commentaries, such as those written by Haradatta, Prithvīdharācārya, Srīkantha, Śatānanda and others ; *vide* Nos 24 and 25 *infra*.

The following works and authors are mentioned in the commentary ;—

देवीभागवतम् । वामनपुराणम् । यास्कः ॥

**Beginning :**

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

प्रथमवर्गप्रथमा ऋक् ॥

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥

अस्यार्थः। हे जातवेदः जातप्रज्ञ अग्ने त्वं हिरण्यवर्णां हिरण्यस्य सुवर्णस्य वर्णः कान्तिः तद्वद्वर्णो यस्यास्तां हरिणीं हरितवर्णां हरिणीरूपधरां वा । श्रीर्धृत्वा हरिणीरूपमरण्ये सञ्चचार हेति पुराणात् । सुवर्णरजतस्रजां सुवर्णस्य पुष्पाणि सुवर्णानि एवं रजतस्य रजतानि तेषां स्रजः माला यस्यास्तां स्रक् साहचर्यात् पुष्पाणीत्यवगम्यते। पुष्पसादृश्यात् पुष्पफलेत्यादिना लुक् । आ पञ्चैव हलन्तानामित्यादि । यद्वा सुवर्णरजतविकृतशृङ्खलां सुष्ठु वर्णो यस्य तत्सुवर्णं यद्रजतं तत्पुष्पस्रजां तद्विकृतश्रृङ्खलां वा चन्द्रां चन्द्रवत् प्रकाशमानां तद्रूपेणावस्थितां वा ॥ हिरण्मयीं हिरण्यस्वरूपां हिरण्यविग्रहां वा लक्ष्मीं लक्षणवतीं लाक्षालक्षणाद्वेद इति निरुक्तात् एवं रूपां श्रियं मे मह्यं मदर्थं आवह आह्वय अग्नेर्देवहोतृत्वादाह्वानं तदधीनमिति भावः ॥

**End :**

ताम्म आवह जात . . . . . पुरुषानहम्.

अस्यार्थः । इयमृक् द्वितीयया ऋचा व्याख्याता । प्रभूतं भूयिष्ठं गावः गाः दास्यः । परिज्ञाताः उभयत्र शसर्थे जस् । इयान् विशेषः । इति तृतीयो वर्गः ॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् । ओं तत्सत् ।

---

## No 24. श्रीसूक्तभाष्यम
## ŚRĪSŪKTABHĀSYAM

Substance, palm-leaf Size, $17\frac{1}{2} \times 1\frac{1}{2}$ inches Pages, 8 Begins on folio 33*a* Lines, 7 on a page Character, Grantha Appearance, new. Injured Complete

Same as No 23

The other work found in this MS. is Śrīsūktabhāsyam (fol. 1*a*) by Ranganāthamuni (*vide* No. 26).

Though this commentary is identical with No. 23, yet this does not contain the ślōka (वेदार्थस्य . . श्वरः) ; but there is a colophon at the end of this MS. which ascribes the work to Haradatta.

**Colophon** :—श्रीस्तुतिव्याख्या हरदत्तेन कृता समाप्ता।

---

## No 25. श्रीसूक्तभाष्यम्.
## ŚRĪSŪKTABHĀSYAM.

Substance, palm-leaf. Size, $15\frac{3}{4} \times 1\frac{1}{4}$ inches. Pages, 45 Begins on folio 1. Lines, 6 on a page. Character, Grantha. Appearance, new In good order.

Complete.

The commentary of Gōmatha Raṅganātha on the Srīsūkta.

This manuscript contains also Sandhyāvandanabhāsyam (fol. 24*a*).

The peculiarity of this commentary is that it interprets the word जातवेदस् to mean the God Visnu instead of Agni, the God of Fire, and that it quotes authorities from Vēdas, Smrtis and Purānas in support of the interpretation; I have therefore given a long extract to show fully the nature of the work. In this matter of interpretation it is only a type of the Vaisnavite commentaries which always interpret the names of gods to mean Visṇu whenever it is convenient to do so.

**Beginning:**

यामाहुः श्रुतयः सर्वाः पुंप्रधानेश्वरेश्वरीम् ।
अशेषलोकजननीं लक्ष्मीं कमलवासिनीम् ॥

यत्पादाम्भोजघटिता प्रणतिर्दुर्लभान्यपि ।
पदानि परमां मुक्तिं सूते तां श्रियमाश्रये ॥

श्रियस्सूक्तमधीतं यत् सुजपं मङ्गलावहम् ।
अशरण्यशरण्यं तद्व्याकुर्मो भोगमोक्षदम् ॥

. . . तत्र तावत् श्रुतयः । श्रद्धासूक्ते श्रद्धया देवो देवत्वमश्नुते । श्रद्धा प्रतिष्ठा लोकस्य देवी . . . . . सर्वपुरुषार्थसाधकत्वं श्रुतम् । तस्मादवश्यं सूक्तादीनामर्थज्ञानं सम्यगादरणीयम् । तज्ज्ञानार्थमिदमपि सूक्तं व्याकुर्महे । श्रीसूक्तं व्याख्यास्यते ।

ओं ॥ हिरण्यवर्णां . . . . . ममावह ॥

सर्वेश्वरी लक्ष्मीर्मोक्षप्रदायिनी । आद्ययावाह्यते देवी श्रीनिवासाद्धरिप्रिया ॥ हिरण्यवर्णामित्यादि हे जातवेदः लक्ष्मीपते स्वतः सिद्धो वेदः धनं वा ज्ञानं वा यशो वा यस्य स जातवेदः स्वतःसिद्धं सर्वज्ञत्वं

सर्वैश्वर्यादिकं साक्षाल्लक्ष्मीपतेरेव नान्यस्य कस्यचित् । अग्न्यादिसोमसूर्य-वैश्रवणचतुर्मुखादीनां ज्ञानबलैश्वर्यादिकं स्वपदलाभादिकं च भगवदाय-त्तमिति सर्वैःशास्त्रैस्समर्थ्यते । तथाहि । चतुर्मुखस्य तावत् ॥

महाभारते ॥

युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः ।
पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुमः ॥

राजधर्मे ॥ शिवस्य

महादेवः सर्वमेधे महात्मा हुत्वात्मानं देवदेवो बभूव । विश्वान् लोकान् व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान् कृत्तिवासाः ।

शतमखस्य वैष्णवे ॥

इष्ट्वायमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप्तमन . . न्त्रादिमहं द्रक्ष्यामि चक्रिणम् ॥

अग्न्यादित्यसोमानां तेजोदास्त्वमसि । अग्नेर्वर्चोदास्त्वमसि । सूर्यस्य द्युम्नो(म्र)दास्त्वमसि चन्द्रमस इति पुनरप्यत्रैव । अग्निं त्रै जातं पाप्मा जग्राह । तदेवाहुतिभिः पाप्मानमपाघ्नन् । त्रिते देवा अमृजतैतदेनः । त्रित एतन्मनुष्येषु मामृजे । भीषास्माद्वातः पवते । इत्यादि

यमश्च । अहममरवरार्चितेन धात्रा सम इति लोकहिताहिते नियुक्तः ।
हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥

सर्वेषां लोकपालानां । काश्यपीये ।

ब्रह्माद्याश्च सुरास्सर्वे मुनयश्च तपोधनाः ।
एवं ते त्वत्पदच्छायां आश्रित्य कमलेश्वरेति ॥

ब्राह्मे ॥

एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः ।
तदंशाः शक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥

मङ्कणसंहितायां ॥

श्यामः किरीटी देवेन्द्रो वज्रहृद्विश्वनन्दनः ।
श्रीपूजानिरतो भोगी योऽसौ पुष्णातु मे श्रियम् ॥
वह्निर्विश्वभुगत्युग्रः शक्तिदेवमुखो भृगुः ।
पद्मापादार्चनपरो रक्तः पुष्णातु मे श्रियम् ॥
गरुत्मतो निभः पाशी वरुणो यादसां पतिः ।
सुधासूक्त्यर्चनपरः स्निग्धः पुष्णातु मे श्रियम् ॥
प्रवर्तयति लोकांस्त्रीन् जीवयत्यपि मारुतः ।
ख्यातिश्चाराधनपरः प्रीतः पुष्णातु मे श्रियम् ॥
सामर्ग्यजुर्मयीं देवीं देवगर्भां मनस्विनीम् ।
लोकेश . . विभूतीनां कारणं यन्निरीक्षणम् ॥

इति । भगवद्व्यतिरिक्तानां सर्वेषां देवानां स्वरूपगुणविभवादिकं भगवदधीनमिति प्रपञ्चितम् ।

तस्मादत्रजातवेदश्शब्दः सर्वनिर्वाहकस्य श्रियःपतेर्वाचक इति परमात्मसूक्ते जातवेदश्शब्दः परमात्मनि प्रयुज्यते । जातवेदसे सुनवाम सोममिति परमात्मनि प्रयुक्तानां एवं विधानां रूढिमपहाय योगेनैतद्वाचकत्वं भगवता शारीरकमीमांसासूत्रकारेण बादरायणेन । आकाशस्तल्लिङ्गात् । प्राणस्तथानुगमात् । वैश्वानरस्साधारणशब्दविशेषात् ॥ इत्यादि सूत्रैस्सुदृढेन न्यायेन निरूप्य निर्णीतम् ॥

**End:**

अन्तिमेनाद्यसूक्तार्थं तात्पर्यातिशयात्पुनः ।
अनन्यगामिनीं देवीं सन्निधौ तां नियच्छति ॥
ताम्म अवह . . . पुरुषानहम् ॥

ता।मित्यादि पूर्ववत्। अयमत्र विशेषः। प्रभूतं पूर्वोक्तकृष्यजीवन दासीदासादिकमशेषं धनजातं यस्यां पुंप्रधानेश्वर्यां प्रणिपातप्रसन्नाया-मखिललोकनान्दिन्यां (अस्मज्जनन्यां प्रभूत)मनवधिकातिशयं विन्देयं लभेय तां सर्वप्रदानपर्याप्तसमृद्धिमतीं करुणास्नानतमुखीं सर्वेश्वरीं श्रियं स्वचरणारविन्दपरिचर्यैकविनोदिनः मे मयि जातवेदः श्रियःपते अनप-गामिनीं अन्यत्रापि अपगमनशङ्कारहितां अनेनार्चनहोमजपतर्पणादिकं कुर्वीतां तस्याः प्रसन्नपावनकान्तिशान्त्याकरवदनारविन्दविनिवेशित मनोनयनबुद्धीनां तच्चरणारविन्दाम्भोजयजनभजननमनस्मरणकीर्तनादि परममङ्गलाचाराणां तत्पदाम्भोजाविन्यस्तसमस्तभाराणां अनन्यभावानां तच्चरणवरणचारित्रपराणां ऐहिकमामुष्मिकं वा पुरुषार्थजातं परमपदा-धिष्ठातृभूतपरमपुरुषचरणारविन्दनित्यैकरसिकपरमसूरिपरिषन्मनीषितादि-कमपि सुलभमिति श्रुतिस्मृतीतिहासपुराणादिसिद्धान्तः ॥

महालक्ष्मीशदासीये सर्वशास्त्रार्थनिर्णये ।
श्रीसूक्तभाष्ये वक्ष्येस्मिन् क्षमध्वं पुरुषोत्तमाः ॥

Colophon—इति श्रीगोमठरङ्गनाथविरचितं श्रीसूक्तभाष्यं समाप्तम् ॥

The following works and authors are quoted in the commentary :—

| | |
|---|---|
| श्रद्धासूक्तम् ॥ | ब्राह्मपुराणम् ॥ |
| वैष्णवसूक्तम् ॥ | सनत्कुमारः ॥ |
| आरण्यपर्वणि आर्ष्टिषेणः ॥ | लैङ्गेऽसुपस्तोत्रम् ॥ |
| मेधासूक्तम् ॥ | विष्णुस्मृतिः ॥ |
| अदितिसूक्तम् ॥ | स्वायंभुवम् ॥ |
| पृथिवीसूक्तम् ॥ | बोधायनः |
| वैष्णवपुराणे मैत्रेयपराशरसंवादः ॥ | वसिष्ठस्मृतिः |

पाद्मपुराणम् ॥
महाभारतम् ॥
राजधर्मः ॥
यमः ॥
काश्यपीयम् ॥
मङ्कणसंहिता ॥
परमात्मसूक्तम् ॥
शारीरकमीमांसासूत्रकारः बादरायणः ॥
धनदीयम् ॥
नाममाला ॥
भविष्योत्तरपुराणम् ॥
ईश्वरसंहिता ॥
लैङ्गम् ॥
दुष्षहः ॥
रामायणम् ॥

---

## No. 26. श्रीसूक्तभाष्यम्.

## ŚRĪSŪKTABHĀṢYAM.

Substance, palm-leaf  Size, 17½ × 1½ inches  Pages, 64  Lines, 6 on a page.  Character, Grantha  Appearance, new  Injured

This codex contains another commentary on the Śrisūkta beginning on folio 33*a*, which is noticed in No 24.

This commentary is another copy of No. 25, but differs from it in having different readings in many places; just before the stanza given at the end of the work beginning with महालक्ष्मी, this codex gives an additional stanza which runs as follows :—

यतीन्द्रमाहानसिकात् प्रणतार्तिहराद्गुरोः ।
सत्सम्प्रदायसिद्धोऽर्थः श्रीसूक्तस्य विनिश्चितः ॥

The colophon at the end runs as follows :—श्रीरङ्गनाथमुनिविरचितं श्रीसूक्तभाष्यं समाप्तम् ॥ धातुवर्षे मकरमासे पञ्चदशदिने श्रीमन्नैध्रुपा(वा?)न्वयसम्भूतरामानुजदासालिखितं श्रीसूक्तभाष्यं सम्पूर्णम् ॥

---

## No 27. श्रीसूक्तभाष्यम्.

## ŚRĪSŪKTABHĀSYAM.

Substance, paper Size, 7⅜ × 6 inches. Pages, 11. Lines, 24 on a page. Character, Telugu. Appearance, new. In good condition

Complete. Bound with the leaves wrongly arranged Written on folios 57 and 66 to 70

The author of the commentary is not known

This commentary is mainly an abridgment of the one noticed in 25 and 26 adopting the same language, but omitting those portions which seem to be unnecessary for the understanding of the meaning of the text, while preserving the spirit of the interpretation.

**Beginning:**

श्रीसूक्तविशिष्टाद्वैतभाष्यम् । हरिः ओं ॥

हिरण्यवर्णां . . . . . . ममावह ॥

हिरण्यवर्णामिति । हे जातवेदः जातं प्रादुर्भूतं स्वतस्सिद्धं वेदः धनं ज्ञानं वा यस्य स जातवेदाः श्रीपतिः . . . . . .

**End:**

सुलभमिति सकलश्रुतिस्मृतीतिहासपुराणसिद्धान्तः ॥

**Colophon:**—इति वेदार्थे लक्ष्म्याः श्रीसूक्तव्याख्यानम् ॥

The following other works are contained in this codex :—Nīlakaṇṭhavijayaḥ (fol 1*a*), Mahānāṭakam, Hanumadrāmayaṇasahitam (fol 3*a*), Hariharatāratamyam (fol. 53*a*), . . . . Sāmudrikaśāstram (fol. 58*a*), Anēkārthadhvanimañjarī (fol. 74*a*).

क्रोधनाषाढके कृष्णद्वादशीसौम्यवासरे ।
लिखितोऽयं वेङ्कटाद्रिकृष्णरायेण सादरम् ॥

The following works and authors are quoted in the commentary :—

| Folio | Works and Authors. | Folio | Works and Authors. |
|---|---|---|---|
| 1 | श्रुतयः. | 3 | लैङ्गम्. |
| ,, | स्मृतयः. | ,, | नारदीयम्. |
| ,, | बादरायणसूत्रम्. | ,, | ब्राह्मणम्. |
| ,, | विष्णुपुराणम्. | ,, | बोधायनः. |
| ,, | विष्णुपुराणम्. | ,, | नारदीयम्. |
| 2 | स्वायम्भुवम् (आगमः). | ,, | भगवद्गीता. |
| ,, | नाममाला (स्तोत्रम्). | ,, | स्मृतिः |
| ,, | श्रुतिः. | 4 | लैङ्गम्. |
| ,, | मङ्कणसंहिता (देवीविषयः) | ,, | पुराणवचनानि (मार्कण्डेयम्). |
| ,, | भविष्योत्तरम्. | ,, | नारदीयम्. |
| ,, | पुराणश्लोकाः | ,, | श्रुतिः |
| ,, | मङ्कणसंहिता. | 5 | पुराणश्लोकः |
| ,, | काश्यपीयम्. | ,, | पौराणिकाः |
| | | ,, | श्रुतिः |

No. 28. श्रीसूक्तव्याख्या.

SRĪSUKTAVYĀKHYĀ.

Substance, palm-leaf. Size, 18 × 1¼ inches Pages, 8. Lines, 7 on a page. Character, Grantha Appearance, old In good condition.

Complete. Begins on folio 33*a*

The other work contained in this codex is Tarkasaṅgraha-vyākhyā (fol. 1*a*)

The commentary, on comparison, is identical with that printed under the name of Pṛthvīdharācārya, but there is nothing in the manuscript itself to establish the authorship

**Beginning:**

हिरण्यवर्णां हरिणीं . . . . . ममावह ॥

हिरण्यवर्णामिति पञ्चदशर्चां व्याख्यानमाह । हिरण्यवर्णामिति । हे जातवेदोऽग्ने हिरण्यवर्णां स्वर्णकान्तिं हरिणीं हरितवर्णां हरिद्राभां सुवर्णरजतस्रजां हेमरौप्यकमलक्लृप्तमालिकां चन्द्रां सकलजनसन्तोषकरीं हिरण्मयीं हिरण्यस्वरूपां एतादृशीं लक्ष्मीं मम सर्वाभीष्टसाधनाय आवह प्रेषय ॥ 1 ॥

**End:**

ताम्म आवह . . . . . पुरुषानहम् ॥

तामिति । हे जातवेदोऽग्ने यस्यां लक्ष्म्यामागतायां अहं प्रभूतं पुष्कलं हिरण्यं धनं गावः गोमहिष्यादीन् दास्यः दासीदासजनान् अश्वान् गजतुरगरथादीन् पुरुषान् बन्धून् पुत्रपौत्रमित्रादीन् विन्देयं लभेय । अनपगामिनीं निवृत्तिरहितां तादृशीं लक्ष्मीं मम मदर्थं आवह आह्वानं कुरु ॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
श्रियः पञ्चदशर्चञ्च श्रीकामः सततं जपेत् ॥

पञ्चदशर्चां व्याख्या ॥ हिरण्यवर्णामिति पञ्चदशर्च(स्य) जपे विनियोगः । ध्यानम् ॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च ।

मंणिमकुटविचित्रालङ्कृता पुष्पजालैः
दिशतु भुवनमाता सन्ततं श्रीः श्रियं नः ॥

---

## No 29. श्रीसूक्तव्याख्या.
## ŚRĪSŪKTAVYĀKHYĀ.

Substance, palm-leaf Size, 15½ × 1 inches Pages 13 Lines, 5 on a page Character, Telugu Appearance, new In good condition

Complete Begins on folio 95*a*

The commentary given in this codex is the same as No. 28.

The following other works are found in the MS under notice :—

| | Folio |
|---|---|
| Gāyatrīhrdayam | 1*a* |
| Gāyatrīvandanastōtram | 8*a* |
| Śāpavimōcanamantraḥ | 9*a* |
| Gāyatrīmantra[illegible]jan | 10*a* |
| Gāyatrīcaturvimśatinyāsaḥ | 10*b* |
| Gāyatrīyantram | 18*a* |
| Gāyatrīpañjaram | 23*a* |
| Bhūśuddhimantraḥ | 30*b* |
| Gāyatrībhujangaḥ | 34*a* |
| Gāyatrībrahmāstraprayōganyāsamantraḥ | 35*a* |
| Gāyatrī Sāvitrī Sarasvatī-Tarpanavidhiḥ | 36*a* |
| Gāyatryastōttaraśatanāmāni | 37*a* |
| Gāyatrīkavacaḥ | 39*a* |
| Rudravidhānam | 42*a* |
| Śūlinīmantraḥ | 56*a* |
| Śāktamantrāgamaḥ | 60*a* |
| Pañcasimhāsanēśvarīsūktam | 63*a* |
| Uttarasandhyāmrtyulāngalastōtram | 69*a* |
| Pāpapurusadahanam | 72*a* |
| Bhūtaśuddhimahāmantraḥ | 74*a* |
| Prāṇapratisthā | 76*a* |
| Nārāyaṇahrdayastōtram | 78*a* |
| Pratyangirāmantraḥ | 81*a* |
| Sarasvatyastōttaraśatanāmāvaliḥ | 87*a* |
| Śuddhaśaktikhadgamālāstōtram | 90*a* |
| * * * | |
| Vibhūtidhāraṇam | 102*a* |
| Śarabhasāluvamantraḥ | 105*a* |
| Śarabhāstōttaraśatanyāsaḥ | 109*b* |

| | Folio |
|---|---|
| Śarabhakalākarsanamālıkā .. .. .. | 110*a* |
| Daksınāmūrtyastōttara śatam .. .. | 113*a* |
| Mahāsankalpah .. | 118*a* |
| Laksmīganapatimantrah | 125*a* |
| Ganapatidvādaśanāmāni | 126*a* |
| Sarasvatīstavarājah .. | 126*a* |
| Gārudadvādaśanāmāni.. | 126*b* |
| Hanūmaddvādaśanāmāni .. .. .. | 127*a* |
| Gurupādukātrayamantrah .. .. .. | 128*a* |
| Daksınāmūrtikavacah .. | 129*a* |
| Hanūmanmālāmantrah | 132*a* |
| Nārasimhamantrah .. | 133*a* |
| Tryambakanyāsah .. | 134*a* |
| Pañcavaktrahanūmanmantrah .. .. | 136*a* |
| Hanumadyantrah with Tel Tīkā .. .. | 141*a* |
| Ganapatyastōttaraśatanāmāni .. .. | 143*a* |
| Sūryāstōttaraśatanāmānı. | 146*a* |
| Gōpalastōttaraśatanāmāni .. .. .. | 149*a* |
| Gōpalāstōttaraśatam .. | 152*a* |
| Śivāstōttaraśatanāmāni | 155*a* |
| Dēvyastōttaraśatanāmāni | 158*a* |
| Lingapūjāvidhih .. | 160*a* |
| Śıvaganapatistōtram .. | 164*a* |
| Pārthivapūjāvidhıh .. | 165*a* |
| Vanadurgāstōtram .. | 174*a* |
| Varāhōpanisad .. .. | 192*a* |


---

## No 30. श्रीसूक्तव्याख्या.
## ŚRĪSŪKTAVYĀKHYĀ.

Substance, palm-leaf Size, 18½ × 1¼ inches Pages, 8 Lines, 5 on a page Character, Grantha Appearance, new Not injured.

Complete Begins on folio 34*a*

Same as No 28, but after the commentary of the 15th hymn, the following passage is found —

एवमर्थानुसन्धानपुरस्सरं श्रीदेव्याः पञ्चदशार्चसूक्तस्य जपहोमतर्पणं ब्राह्मणाराधनं प्राप्तब्रह्मचर्यः पुमान् कुर्वन् इह सकलसौभाग्यनिदानं परत्र परमसुखं भजतीति निखिलमुनिमतसिद्धान्तः । व्याख्यामेतान्तु यो भक्त्या वदेच्छृणुयाद्बुधः साक्षान्नारायणवधूरिष्टं प्रयच्छति ॥

The following other works are found in the codex Navōnavōbhavatītisrutyarthavicārah (fol. 1*a*), Adhikārasangrahah with commentary (fol. 7*a*), . . . . and Nıksēpacintāmanih (fol. 38*a*).

## No. 31. ऋग्भाष्यम्.
## RGBHĀSYAM.

Substance, country paper Size, 10 × 4¼ inches Pages, 88 Lines, 16 on a page Character, Dēvanāgarī Condition, good

Complete Begins on folio 47*b*.

The commentary of Ānandatīrtha on the Rgvēda, in the form of verses. He touches only on certain important points. The names of various deities mentioned in the Vēda are interpreted to refer to the God Visnu. The commentary ends with the 2nd Adhyāya of the 1st Astaka *Vide* the remark under No 16

The following are other works found in the codex —

| | Folio. |
|---|---|
| Kāthakōpanisadbhāsyam .. .. .. .. | 1*a* |
| Satpraśnōpanisadbhāsyam .. .. .. .. | 9*a* |
| Īśavāsyōpanisadbhāsyam .. .. .. .. | 12*b* |
| Māndūkyōpanisadbhāsyam .. .. .. .. | 16*b* |
| Talavakārōpanisadbhāsyam .. .. .. .. | 23*b* |
| Atharvanōpanisadbhāsyam .. .. .. .. | 40*b* |

* *

**Beginning.**

नारायणं निखिलपूर्णगुणार्णमुद्यत्
सूर्यामितद्युतिमशेषनिरस्तदोषम् ।
सर्वेश्वरं गुरुमजेशनुतं प्रणम्य
वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥

ओमशेषगुणाधार इति नारायणेऽप्यसौ ।
पूर्णभूतिवरोऽनन्तसुखो यद्वचाहृतीरितः ॥
गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः ।
भारतीज्ञानरूपत्वाद्भर्गो ध्येयोऽखिलैर्जनैः ॥
प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः ।
स पूर्णत्वात्पुमान्नामा पौरुषे सूक्त ईरितः ॥

स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च ।
स एवाखिलशब्दार्थः इत्याहोपनिषत्परा ॥

तावा एक ऋच इति विशेषेणाप्यृगर्थताम् ।
यो देवानामिति श्रुत्वा देवनाम्नां विशेषतः ॥

स्पष्टत्वाचद्रतत्वेन तत्राहाग्रेऽग्निनामकम् ।
अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् ॥

एवमेवाह भगवान्निरुक्तिं बादरायणः ।
मय्येवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने ॥

तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये ।
इति तेनाग्निशब्दोऽयमग्र एवाभिपूज्यताम् ॥

अग्र्यत्वमग्रनेतृत्वमतिसङ्गाङ्गनेतृताम् ।
आहतं स्तौम्यशेषस्य पूर्वमेवं हितं प्रभुम् ॥

ऋत्विङ्क्रियामकत्वेन यज्ञानां ऋत्विजं सदा ।
द्योतनादि(न्नि)जया कान्त्या स्तुत्या व्यवहृतेरपि ॥

गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः ।
अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता ॥

इन्द्रियाग्निषु चार्थानां यद्धोमा होतृनामकः ।
रतिधारकोत्तमत्वात्स रत्नधातम ईरितः ॥

स पूर्वैर्नूतनैरेभ्यैर्विज्ञानादृषिनामभिः ।
ईड्यो देवादिभिस्सर्वैः स च देवानिहानयेत् ॥

तेनैव रयिमाप्नोति वित्तविद्याधनात्मकम् ।
दिवसे दिवसे नित्यं पुष्टिमेव न हीयताम् ॥

* * *

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमदृग्भाष्ये प्रथमोऽध्यायः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमदृग्भाष्ये प्रथमाष्टके द्वितीयोऽध्यायः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं श्रीमदृग्भाष्यं समाप्तम् ॥

---

## No 32. ऋग्वेदब्राह्मणम्.
## ṚGVĒDA-BRĀHMANAM.

Substance, palm-leaf (Śrītāla) Size, $14\frac{3}{4} \times 2$ inches Pages, 263. Lines, 10 on a page Character, Grantha. Appearance, old In good condition Correct

The Brāhmana portion of the Ṛgvēda in eight Pañcikās, each consisting of 5 Adhyāyas This Brāhmaṇa is also called Bahvṛcabrāhmana and Aitareyabrāhmana

The name Aitarēya Brāhmana seems to have been applied to the Brāhmaṇa of the Ṛgvēda in reference to its having been borrowed from another Vēda, or Śākhā or branch of the same Vēda, as the word Aitarēya indicates " belonging to another " (sic Vēda). But it was supposed that the word was the name of a sage who composed the work; and a story was invented in support of the etymology and the belief; and it is contained in the following passage :—

प्रवृत्तस्य तु ब्राह्मणस्यैतरेयकत्वे संप्रदायविद एतामाख्यायिकामाचक्षते। कस्य चित् खलु महर्षेर्बह्व्यः पत्न्यो वर्तन्ते। तासां मध्ये कस्याश्चिदितरेति नामधेयम्। इतरायाः पुत्रो महीदासाख्यः कुमारः। एतच्चारण्यकाण्डे समाम्नायते "एतद्धस्म वैतद्विद्वान् महीदास ऐतरेयः" तदीयस्य पितुर्भार्यान्तरपुत्रेष्वेव स्नेहातिशयः न तु महीदासे। ततः कस्यां चित् यज्ञसभायां महीदासमवज्ञायान्यान् पुत्रान् स्वोत्सङ्गे स्थापयामास। तदानीं खिन्नवदनं

महीदासमवगत्येतरा्रखा तन्माता स्वकीयकुलदेवतां भूमिमनुसस्मार । सा च भूमिर्देवता दिव्यमूर्तिधरा सती यज्ञसभायां समागत्य महीदासस्य दिव्यं सिंहासनं दत्त्वा तत्रैनमुपवेश्य सर्वेष्वपि कुमारेषु पाण्डित्याधिक्य मवगमय्यैतद्ब्राह्मणप्रतिभासनरूपं वरं ददौ । तदनुग्रहात्तस्य महीदासस्य मनसाग्निर्वै भूतानामवम इत्यादिकं स्तृणुत इत्यन्तं चत्वारिंशदध्यायोपेतं ब्राह्मणं प्रादुरभूत् । तत ऊर्ध्वम् अथ महाव्रतमित्यादिकम् आचार्या इत्यन्तम् आरण्यकव्रतरूपं च ब्राह्मणम् आविरभूदिति ॥ Preface to Śāyanācārya's com. of the Aitarēya Brāhmana.

There was a sage who had many wives, and one of them was named Itarā. She had a son whose name was Mahīdāsa The father neglected him and loved the other sons more than Mahīdāsa; and at a sacrifice he allowed all the other sons to sit on his lap, but refused the honor to Mahīdāsa. Thereupon Itarā prayed to the Goddess of Earth, who appeared at once and offered a divine throne to Mahīdāsa and seated him there. The Goddess then made him a great scholar Enlightened by the boon of the Goddess of Earth, he composed a Brāhmaṇa and an Āranyaka, which are known by the names of the Aitarēya Brāhmana and the Aitarēya Āranyaka.

The Aitarēya Brāhmana belongs to the Śākalyaśākhā just as the Sāṅkyāyana or Kausītakī Brāhmana does to the Bāskalaśākhā They treat however of the same subjects, but differ considerably in their views. The Aitarēya Brāhmaṇa is divided into eight Pañchikās or pentads, each of which contains five Adhyāyas; and the whole work is therefore composed of forty chapters. The last ten chapters are supposed to be later additions. The following are the subject matter of the forty Adhyāyās

Adhyāyās 1 to 13 treat of the duties of the Hotr priest in the Agnistōma sacrifice.

Adhyāya 14 explains the meaning of the term Agniṣṭōma, and other matters.

Adhyāyas 15 to 17 describe the Ukthya, Ṣōḍaśa, Atirātra and other sacrifices.

Adhyāya 18 contains the rules to be observed by the Hotṛ priests.

Adhyāyas 19 to 24 treat of the duties of the Hotṛ priests at the twelve minor sacrifices.

Adhyāya 25 treat of the expiatory ceremonies to be performed by the sacrificer Yajamāna, the time of performing the Agniṣṭōma sacrifice, and the duties of Brahman

Adhyāyas 26 to 30 treat of the duties of the Grāvastut, Subrahmanya, and the six minor priests at the Sōma sacrifice.

Adhyāyās 31 to 40 treat of the sacrifices to be performed by a Kṣatriya, and the mutual relation of the Brāhmans and the Kṣatriyas.

The Aitarēya Brāhmana refers to the Kausītaka and Paingya in a passage occurring in the latter part of it, which is however considered to be an interpolation; and so the work is supposed to be more ancient than the latter

It was edited by Dr Haug with an English translation in 1863 and also in the Bibliotheca by Rājēndra Lāla Mitra and Satyavrata Svamin Th Aufrecht edited the text in the Roman character with extracts from the commentary of Sāyaṇa in 1879

The last folio gives an index, written in ink, by the same person who wrote the endorsement, showing the folio, page of the folio and line of the page of the beginning of each Adhyāya of the Pañcikā.

Then comes the following :—

"Here ends the Bahvrca Brāhmaṅa, a portion of the Rig-vedah. Complete in eight Panchakās, Grantham character.

*Calicut*, 1825. C. W. Whish."

Another index showing the folio, &c of the beginning of each Pañcikā follows

"Index of the 8 Panchakas. (Memo.—Each Panchaka has 5 chapters.)

"The Brāhmana of the Rig-vedah in one volume.

*Calicut*, 1825. C. W. Whish."

The fly-leaf in the beginning contains the following note —

"Vol. IV of the Rig-Vedah —This volume contains the Bahvricha Brāhmana, a portion of the Rig-Vedah complete in eight Panchikas

*Calicut*, 1825. C W. WHISH."

**Beginning:**

अग्निर्वै देवानामवमो विष्णुः परमः । तदन्तरेण सर्वा अन्या देवता । आग्नावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायन्निर्वपन्ति . . . . . . . . .

**End:**

अपि ह यद्युस्याम्मे (द्यस्याश्म) मूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते स्तृणुते ॥ 5 ॥

**Colophon**:—अष्टमपञ्चिकायां पञ्चमोऽध्यायः ॥ हरिः ओं ॥

---

## No. 33. ऋग्वेदब्राह्मणम्.

## RGVEDA-BRAHMANAM

Substance, paper Size, $12\frac{1}{2} \times 8$ inches. Pages, 308 Lines, 20 on a page Character, Telugu. Appearance, old In good condition Complete.

Begins on folio 11*a*. The other works contained in this codex are:—Contents (fol. 1*a*), Mahāmantraniruktabrāhmanam (fol. 167*a*), Rgvēdanīghaṇṭu (fol. 244*b*), Rgvēdāruṇam (fol 259*b*), Ṛgvēdabrāhmaṇabhāṣyam (fol. 290*a*)

Another copy of the work described in No. 32.

**Colophon:**

अध्यायः समाप्तः ॥ अथातो ब्रह्मणः परिमरः । यो ह वै त्रीन् पुरोहितांस्त्रीन् ॥ . . . . . . ऐन्द्रेण महाभिषेकेण तुरः कावषेयाष्टौ ॥ ऋग्वेदाम्नाये अष्टमपञ्चिकायां पञ्चमोऽध्याय. ॥

---

## No 34. ऋग्वेदब्राह्मणम्.
## RGVĒDA-BRĀHMANAM

Substance, palm-leaf Size, 15½ × 1 inches Page, 70 Lines, 6 on a page Character, Telugu Appearance, old Slightly injured

Contains the first and the seventh Pañcikās of the Brāhmana. Three Khandas at the end of the 5th Adhyāya of the 1 Pañcikā are omitted

**Beginning** of Pañcikā I

अग्निर्वै देवानामवमो विष्णुः . . . . . . . . .

**End:**

तस्मादुपांशु वाचा चरितव्यं। सोमे राजनि क्रीते गन्धर्वेषु हि तर्हि वाग्भवति साम्नावेव प्रणीयमाने पुनरागच्छति ॥ 27 ॥

**Beginning** of Pañcikā VII.

अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामो हनूसजिह्वेन्द्रस्तोतुः श्येनं पक्ष उद्गातुः कन्थः ककुद्रः ॥

**End:**

तदाहुर्यस्य सायं दुग्धं सान्नाय्यं । तदाहुर्यस्याग्निहोत्र्युपावसृष्टा। तदाहुर्य आहिताग्निरुपवसथे म्रियेत । अथातः पशोर्विभक्तिः ॥

अथातः पशोरेका . . . . . . . . . . .

अथातः पशोस्तदाहुर्वाचा पलचथात इष्टापूर्तस्य तेषां यच्च मासानां चत्वारि ॥ हरिः ओं ॥

---

### No 35. ऋग्वेदब्राह्मणभाष्यम्.
### RGVĒDA-BRĀHMANABHĀSYAM.

Substance, palm-leaf. Size, 14¾ × 1¼ inches Pages, 500 Lines, 5 on a page. Character, Nandināgarī. Condition, fairly good. Appearance, old.

Three leaves in the beginning written in Nandināgarī are fragments of some work that cannot be identified Three more leaves in Telugu character contain a few Vargas in the beginning of the Rgvēda.

Contains the commentary by Sāyanācārya from the 3rd Khaṇḍa of the 3rd Adhyāya to the 11th Khaṇḍa of the 13th Adhyāya.

It was edited by Rājēndra Lāla Mitra and Satyavrata Svāmi in the Bibliotheca Indica.

**Beginning:**

The matter of about two lines beginning with सोमप्रवहणीऋं-चोविधाय and ending with राजनम् is omitted.

शकटादधस्ताद्दत्विज उपावहरेयुःयुक्तः शकटे बद्धो विमुक्तः शकटाद्वियोजितः । उभयोरनडुहोर्विमोचनदोषमुपन्यस्यति । यदुभयोर्विमुक्तयोरुपावहरेयुः पितृदेवत्यं राजानं कुर्युरिति । राज्ञः सोमस्य पितृभिः स्वकृतत्वादयं क्षेमो देवयोग्यो न भवेत् । उभयोरनडुहोः शकटयोगेऽपि दोषमाह । यद्युक्तयोरयोगक्षेमः प्रजा विन्देत्ताःप्रजाः परिङ्ववेरन्निति । अप्राप्तस्य धनादेः सम्पादनं योगः प्राप्तस्य रक्षणं क्षेमः योगसहितः क्षेमः योगक्षेमः तदभावः प्रजाः पुत्रादिकां विन्देत लभेत । . . . .

इति ऋग्वेदब्राह्मणे तृतीयाध्याये तृतीयः खण्डः ॥

*   *   *

ऐतरेयब्राह्मणे तृतीयाध्याये षष्ठः खण्डः । समाप्तश्च तृतीयाध्यायः ॥

सोमप्रवाहका अग्निमन्थनीया ऋचस्तथा ।
आतिथा (थ्य) तद्विशेषाग्निश्च (?) तृतीयाध्याय ईरिताः ॥

अथ प्रवर्गादयो वक्तव्याः । . . . . . . . .

इति श्रीमाधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे चतुर्थाध्याये नवमः खण्डः । समाप्तश्चाध्यायः. ॥

अभिष्टोपसत्तानूनप्त्राप्याय निह्नवः कथिताः ।
वर्मसम्भारा व्रतोपायनमेव च ?

अथ सोमक्रयाद्या वक्तव्यास्तं क्रतुं वक्तुमाख्यायिकामाह . . .

इति माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे पञ्चमाध्याये चतुर्थखण्डः समाप्तश्चाध्यायः । समाप्ता च प्रथमपञ्चिका ॥

राजक्रियब्राह्मणमुत्तमादौ वह्नेः प्रणीतिप्रतिपादिकाश्च ।
तथा हविर्धाननिवर्तनाद्धि (र्द्धा) अग्नेश्च सोमस्य च या ऋचस्स्युः ॥

अथ षष्ठाध्यायेऽग्नीषोमीयपशुर्वक्तव्यः . . . . . . .

इति माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे षष्ठाध्याये दशमः खण्डः । समाप्तः षष्ठोऽध्यायः ।

यूपोऽथ यूपाञ्जनमाप्य एवं पर्यग्न्युपप्रैषमथाध्रिगुश्च ।
पशोः पुरोलाशविधिर्मनाता वनस्पतिः षष्ठ इलासृतिश्च ॥

अथ सप्तमाध्याये पशुशेषप्रातरनुवाकौ वक्तव्यौ ॥ . . .

इति श्री . . . . . सप्तमाध्याये ऽष्टमः खण्डः ।

समाप्तश्चाध्यायः ।

पर्यग्नचादेर्विशेषांश्च स्तोकस्वाहाकृतीरपि ।
वपां चाधीयते प्रानरनुवाके विधिं स्तवं ॥

अथापोनप्त्रीयादयो वक्तव्याः । . . . . . . . . . . .

इति माधवीये . . . . . अष्टमाध्याये षष्ठः खण्डः समाप्तश्चाध्यायः ॥

अपोनप्त्रीय तच्छेषावुक्तांश्चाधि . . . . . . . . . . .

इति . . . नवमाध्यायेऽष्टमःखण्डः । समाप्तश्चाध्यायः

ऋतुयाजा द्विदैवत्यास्तद्विशेषा इलास्तुतिः
तूष्णीं शंसप्रशंसा च नवमाध्यायचोदना ।

अथ हावादयो वक्तव्याः

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे दशमाध्याये नवमः खण्डः । समाप्तश्चाध्यायः । द्वितीयपञ्चिका समाप्ता ॥

आहावं निविदं सूक्तमच्छावाकस्य चोदनाम् ।
यजमानपुनर्जन्म ब्रुवतेऽथाधिदैवतम् ।

इत्थमाज्यशस्त्रं प्रउगशस्त्रं निरूपयितुं प्रस्तौति

इति माधवीये . . . . . एकादशोऽध्यायः ॥

एकादशे तु प्रउगप्रशंसां ततो वषट्कारमनुस्तुतिश्च ।
तत्कर्तुरात्मन्यनुमन्त्वणं च ततोऽनिवित(न्निवि)त्प्रैषविशेषमाहुः ॥

अथाहावप्रतिगरादयो वक्तव्याः ।

* * *

इति माधवीये ब्राह्मणे द्वादशे त्रयोदशः । समाप्तश्चाध्यायः ॥

वक्तव्याहावप्रभेदप्रतिगरेण मध्यानुष्टुभः दास्यमानमृत्यो : संन्यस्य चातिक्रमणमथ मरुत्वाद्विधानप्रशंसा . . . . . . . .

तस्मात्कारणाद्वित्वं सम्प्रतिष्ठयोस्त्विति हेत्वोपादयोरेवोपरिष्टादूर्द्ध्वं प्रजननं प्रजोत्पादकमिन्द्रियं दधाति तच्च प्रजाप्त्यै प्रजोत्पादन.य सम्पद्यो वेदनं प्रशंसति प्रजायते प्रजया पशुभिर्य एवं वेदेति ॥

इति त्रयोद्दशाध्याये एकादशः खण्डः ॥

---

## No 36. ऋग्वेदब्राह्मणभाष्यम्.
## RGVĒDA-BRĀHMANABHĀSYAM

Substance, paper Size, 12½ × 8 inches Pages, 328 Lines, 24 on a page Character, Tèlugu Appearance, new In good condition

The commentary of Sāyanācārya on the sixth, seventh and eighth Pañcikās, *i e*, from the 26th to the 40th Adhyāya of Rgvēda-brāhmana, also called Aitarēyabrāhmana

Begins on fol. 290*a*. For the list of other works in the codex *vide* No 33

**Beginning:**

अथाग्निहोत्रं पयसः प्रशंसा तद्दोहनापत्तिविनिष्कृतिश्च । तस्य प्रशंसाप्युदिते च होमौ ब्रह्मर्त्विजो व्याहृतयोऽप्यधीताः ॥ ब्रह्मणः कर्तव्यावविधानेन ग्रावस्तुद्बुद्धिस्थः तस्याग्निष्टोमे कर्तव्यं विधातुमुपाख्यानमाह । देवा हवै सर्व . . . चरौ सत्रं निषेदु . . . स्ते ह पाप्मानं नापजघ्निरे . . . . . . . . . . . . . .

**End:**

आपिह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते ॥ अस्य राज्ञः अनुष्ठातुर्द्विषन् शत्रुर्यद्यश्ममूर्धा पाषाणशिरस्को भवति अतिप्रबल इत्यर्थः। तथाप्ययं कर्मविशेषः शीघ्रमेव एनं शत्रुं स्तृणुते हिनस्ति ॥ अभ्यासो ऽध्यायः समाप्तश्चः ॥

**Colophon** :—इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे चत्वारिंशाध्याये पञ्चमःखण्डः ॥ समाप्तश्चाध्यायः

---

## No 37. ऋग्वेदब्राह्मणभाष्यम्.
## RGVĒDA - BRĀHMANABHĀSYAM

Substance, palm-leaf Size, $17\frac{1}{4} \times 1\frac{1}{4}$ inches Pages, 169 Lines, 7 on a page. Character, Telugu Condition, very much injured. Appearance, old

This is the same commentary by Sāyaṇācārya as the above on the Rgvēda-brāhmaṇa It extends from the 20th Adhyaya to the 25th Adhyāya.

**Beginning:**

इति माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे एकोनविंशाध्याये षष्ठः खण्डः ॥

ज्योतिष्मत्या भरतो द्वादशाहदीक्षाकालो याजनं प्राशं सिश्चन्योऽथ छन्दो द्वादशाहप्रशंसा प्रष्ठादीनां छन्दसां त्वत्र कॢप्तिः । इदानीं द्वादशाहक्रतोः प्रायणीयोद(य)नीयावतिरात्रौ । यच्च दशम(म)हस्तत्तृतीयं वर्जयित्वा यो मध्यगतो यो नवरात्रीर्विधातुमुपक्रमते । अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्सोमो रथन्तरं साम गायत्रीछन्द इति ॥

**End:**

इन्द्रवन्तः इन्द्रविषयतात्पर्यवन्त एव भूत्वा स्तुध्वमित्यनेनैव प्रकारेण एनानुद्रातॄन् प्रति ब्रह्म तद्वाक्यमाह अध्या(भ्या)सोऽध्यायसमाप्त्यर्थः ॥

**Colophon** —इति सायणाचार्यविरचिते ऐतरेयब्राह्मणे पञ्चविंशाध्याये नवमः खण्डः ॥ समाप्तश्चाध्यायः ॥ समाप्ता पञ्चमपञ्चिका ॥

## No 38. ऋग्वेदारण्यकम्
## RGVĒDĀRANYAKAM.

Substance paper. Size, 12½ × 8 inches Pages, 60 Lines, 23 on a page Character, Telugu Appearance, new. In good order

Begins on fol 259*b* This is the same manuscript as No 33

The Āranyaka portion of the Rgvēda It is a supplement to the Aitarēya Brāhmana and consists of five parts or Āranyakās; the first, the fourth and the fifth treating of the Mahāvrata, and the second and the third, of theological metaphysics. The last four chapters of the second part is designated Aitarēyōpanisad and is included in the Upanisads According to a passage quoted in No 32, it was composed by the sage Aitarēya who composed the Brāhmana also The work is ascribed to Āśvalāyana according to the colophon इत्याश्वलायनोक्तमारण्यकं समाप्तम् ॥ with which the manuscripts mentioned in Eggeling's Cat end. Colebrooke has seen the same reference in a manuscript of the book. He gives the substance of a passage in which it is said that an Āraṇyaka was composed by Āśvalāyana and was raised to the dignity of a Brāhmana (Colebrooke's Mis Es., Vol. I, page 307 ) The word आरण्यक means what is to be studied in the forest and is applied to a branch of the Vēdic literature, which was intended to be studied so, as seen from the following passage अरण्याध्ययनादेतदारण्यकमितीर्यते—Preface to Sāyana's commentary of the Taittirīyāranyaka

The work has been published by Rājēndra Lal Mitra in the Bibliotheca Indica at Calcutta (1875) with Sāyana's commentary completely Āranyakas 1–3 have been translated by Max Müller in Vol I of the Sacred Books of the East.

**Beginning:**

हरिः ओम् ॥ भूमिमुपस्पृशेत . . . . . । भद्रं कर्णेभिः . . . । शं न इन्द्राग्नि . . . . . । स्तुषे जनं सुव्रतं

. . . . . . (?) कयानश्चित्र आभुवत् . . . . । स्योना पृथिवी . . . . . । वाङ्मे मनसि प्रतिष्ठिता . . . . । ओं शान्तिः शान्तिः शान्तिः ॥

हरिः ओम् ॥ अथ महाव्रतमिन्द्रो वै वृत्रं हत्वा महानभवद्यन्महानभवत्तन्महाव्रतमभवत्तन्महाव्रतस्य महाव्रतत्वं द्वे एतस्याह्न आज्ये कुर्यादितिहैक आहुः ॥

**End**:

त्रिरात्रं वैदिकेनाध्यायेनान्तरियान्नास्मिन्कथां वदेत् नास्य रात्रौ च न चिकीर्षियिषेत्तदिति वा एतस्य महतो भूतस्य नाम भवति योऽस्यैतदेवन्नाम वेद ब्रह्म भवति ब्रह्म भवति ॥ 14 ॥

अग्निर्वै देवानामवमो विष्णुः परमः नो ऽदीक्षितो महाव्रतं शंसेत् । . . . . . महाव्रतस्यौष्णिही चत्वारि ॥

---

## No 39. ऋग्वेदारुणम्
## RGVĒDARUṆAM.

Substance, palm-leaf. Size, $11\frac{1}{2} \times 1\frac{1}{4}$ inches. Pages, 126. Lines, 6 on a page Character, Telugu. Appearance, old. Much injured. Complete.

Same as No. 38. This does not give the Śāntis in the beginning, but begins with अथ महाव्रतं. The name Āruṇa is a corruption of the word Āranyaka This manuscript was copied by Vēnkatanāthuḍu, son of Vēnkatabhatlu

The following other works are contained in this manuscript:— . . . . . Padaratnam (fol. 64); Saptasankhyā (fol 1); Ṛgvēdapadānukramaṇikā (fol. 64).

### No 40. ऋग्वेदारुणम्.

### RGVEDĀRUNAM

Substance, palm-leaf (Śrītāla). Size, $13\frac{1}{8} \times 1\frac{1}{4}$ inches. Pages, 138. Lines, 6 on a page. Character, Grantha. Appearance, old Slightly injured.

Complete.

Same as No. 38 At the end, अनुक्रमणिका or index is not given.

**Colophon** :—पञ्चमारुणे तृतीयोऽध्यायः ॥

This belongs to the Calicut series

" Here ends the Āranyam of the Rig-vēdah, complete in five Āranyakas ; Grantham character.

*Calicut*, 1825 C W WHISH "

" The Āranyam of the Rig-vēdah in one volume

*Calicut*, 1825 C W WHISH. "

---

## 2. The Sāma Vēda.

The following is an account of the divisions and the sub-divisions of the Sāmavēda ·—

श्रीसामवेदान्तर्गतभेदा उच्यन्ते । पूर्वऋक् उत्तरऋक् इति द्वेधा ।

पूर्वऋचि तु प्रकृतितन्त्राणि । तन्नामानि

| | | |
|---|---|---|
| आग्नेयम्, | त्रिष्टुप्, | आरुणम्, |
| बहुसामि, | अनुष्टुप्, | शुक्रियम्, |
| एकसामि, | इन्द्रपुच्छम्, | महानाम्नी. |
| बृहती, | पवमानम्, | |

उत्तरऋचि तु (1) ऊहतन्त्राणि.

| | | |
|---|---|---|
| दशरात्रः, | अहीनः, | क्षुद्रः. |
| संवत्सरः, | सत्रम्, | |
| ऐकाहः, | प्रायश्चित्तम्, | |

(2) रहस्यतन्त्राणि.

| | | |
|---|---|---|
| दशरात्रः, | अहीनः, | क्षुद्रः. |
| संवत्सरः, | सत्रम्, | |
| ऐकाहः, | प्रायश्चित्तम्, | |

आग्नेयादिपवमानान्तेषु तन्त्रेषु यानि सामानि श्रौतोपयोगीनि तानि अन्यैः सामभिः मिलित्वा त्रिगुणितानि ऊहसामानि ।

आरुणशुक्रिययोः श्रौतोपयोगीनि सामानि यानि तानि अन्यैः सामभिः मिलित्वा त्रिगुणितानि रहस्यसामानि ।

प्रकृत्यां प्रतिखण्डं साम्नां ऊहरहस्यादिष्विव समानसङ्ख्याकत्वनियमो नास्ति । तत्र—

| | | | |
|---|---|---|---|
| आग्नेये | | (खण्डाः) | 12 |
| ऐन्द्रे | बहुसाम्नि | ... | 6 |
| | एकसाम्नि | ... | 6 |
| | बृहत्याम् | ... | 8 |
| | त्रिष्टुभि | ... | 3 |
| | अनुष्टुभि | ... | 4 |
| | इन्द्रपुच्छे | ... | 9 |
| पवमाने | | ... | 11 |

आरुणे पर्वाणि 3–तत्र—

| | | | |
|---|---|---|---|
| प्रथमे | ... | (खण्डाः) | 7 |
| द्वितीये | ... | ... | 7 |
| तृतीये | ... | ... | 8 |
| शुक्रिये | ... | ... | 3 |
| आहत्य प्रकृतिखण्डानि | | | 84 |
| सामसंख्या | ... | ... | 1,446 |

ऊहे विंशतिसङ्ख्यानियमः । दशरात्रे विंशाः संवत्सरादिषु एवमेव विंशतिसङ्ख्याकाः सामनियमाः ।

रहस्ये दशकसङ्ख्याः । प्रतिदशकं दशसामानीति संख्यानियमः ।

ऊहे विंशाः 48; सामानि 960.

रहस्ये दशकाः 20; सामानि 200.

पूर्वर्क्षवः उत्पन्नानि प्रकृतिसामानि । उत्तरर्क्षचः उत्पन्नानि ऊहसामानि रहस्यसामानि च.

The Samhita text of the Sāmavēda consists of two parts, the Pūrvark and the Uttarark. The verses of the former are classified under the five following heads:—

1. आग्नेयम्. Treating of the God of Fire

2. ऐन्द्रम्. Treating of Indra, the God of Rain It includes the portions subsequent to the Āgnēya, viz, Bahusāmi, the Ēkasāmi, the Brhatī, the Tristup, the Anustup and the Indrapuccha

3. पवमानम्. Of the God of Wind.

4. आरुणम्

5. शुक्रियम्

(4, 5) Of the Supreme God, so named because these verses were proclaimed to the world by Aruna, the God of Dawn and by Śukra, the preceptor of the Asuras, respectively.

The text or rk has marks indicating the mode of reciting the hymns; and when the verses are chanted, they are called Sāmāni. The book of Sāmans belonging to the Pūrvark is called Prakrti; those belonging to the Uttarark constitute Ūha and Rahasya. The peculiarity of the Uttarark is that, generally, three verses are grouped together and form one rk; and the first of them occurs in the Pūrvark; and this group of verses is chanted in various ways

with the Sāman so occurring in the Prakrti Hence the Sāmans of the Pūrvark are called Prakrti. The Ūha contains the Sāmans of those Rcas which occur in Āgnēya, Aindra and Pavamāna of the Pūrvark, while the Rcas of the Rahasya are taken from the Āruna and the Śukriya At the end of the Pūrvark, comes the Mahānāmnī, which is considered by some as a part of the Pūrvarcas and by others as a separate work The Sāmans relating to it are called Śakvarī, so named after the kind of Sāman in which it is usually sung.

The Uttarark consists of 21 Adhyāyas on the whole. The Sāmans of Ūha and Rahasya are each divided into the following sections according to their subject matter :—

1. दशरात्रः
2. संवत्सरः
3 ऐकाहः
4. अहीनः
5. सत्रम्
6. प्रायश्चित्तम
7. क्षुद्रः

The Gānas are collections of hymns arranged in a particular way and set to music. The Gēyagānas and the Āranyagānas claim a great antiquity (Burnell's Sāma Brahm., XXXI, and Ārs Brahm , p. XV) According to Weber, the Grāmagēvaganas are erroneously called Vēyagānas In the Grantha edition printed in Southern India by a learned Chandōga scholar, Krsnasvāmi Śrautin, the Pūrvārcika set to music is called Vēyagāna, as is indicated by the colophon इति वेयगानम् समाप्तम् ॥

Th. Benfey has published the two Ārcikas of the Sāma Saṁhita (1848), and Satyavrata Samāśramin, the two Ārcikas and the Gānas with the commentary of Sāyana in the Bibl. Ind , in five volumes (1874–78). The Saṁhitā has been translated into English by Rev J. Steevenson, London, 1842.

The recitation of the Sāmavēda is of two kinds. One is simple and applies to the mere Sūktās or hymns which are taken from the Rgvēda generally, and adopts three Svarās, the Udātta, the

Anudātta, and the Svarita, which occur in the Ṛgvēda and the Yajurvēda The pronunciation of these Svarās among the Brāhmans of the Sâmavēda is quite different from that prevailing among the Brāhmans of the other Vēdas and appears to me more original and scientific The Udātta is high and emphasised, and the Anudātta is low, while the Svarita occupies a somewhat middling position. Apart from the hymns which are metrical, there are lists of words which are unconnected with each other and are pronounced with the above Svarās. In these separate words and also in the metrical hymns, differences are met with in regard to the position of the Svarās. For instance, we have the hymn,

अग्निं दूतं वृणीमहे

accented in the Ṛgvēda in the following manner:—

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।

अस्य यज्ञस्य सुक्रतुम् ॥

In the simple text of the Sāmavēda it is accented in the following manner:—

3 2 3 1 2 3 1 2 3 1 2

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।

1 2 3 1 2 3 1 2

अस्य यज्ञस्य सुक्रतुम् ॥

Now, if we compare the marks of the accents, we see that the figures 1, 2 and 3 stand for the Udatta, Svarita and the Anudātta, respectively. But in the word अग्निम् the second syllable is accented in the Ṛgvēda, while there is no accent (the Udātta) in the word in the Sāmavēda. Again, the word अस्य has the accent on the second syllable in the Ṛgvēda, but none in the Sāmavēda. The same kind of difference is seen between the Pada texts of the Ṛgvēda and the Sāmavēda.

3 2 2 1 2 1 2 3 3 3 1 2

सप्त । त्वा । हरितः । रथे । वहन्ति । देव । सूर्य । शोचिष्केशम् ।

2 2 3 3 3 3

शोचिः । केशं । विचक्षण । वि । चक्षण ॥ End of the Āranya Padapātha, MS No. 62, noticed in the Descriptive Catalogue of the Sanskrit Manuscripts in the Library of the Sanskrit College, Calcutta

सप्त । त्वा । हरितः । रथे । वहन्ति । देव सूर्य । शोचिः केशम् । विचक्षण ।

*Rgvēda*, I 50, 8.

The musical chanting of the Sāmavēda is far more elaborate and complicate than the artificial mode of the recitation of the Rg-vēda and the Yajurvēda There are seven notes, which are called Krusta, Prathama, Dvitīya, Tritīya, Caturtha, Pañcama and Sastha; the last two are also called Mandra and Anusvārya respectively They correspond to the notes of the gamut of Hindu music in the following way .—

| Sāmavēda | Hindu music | |
|---|---|---|
| Prathama .. | .. Madhyama .. | .. ma. |
| Dvitīya .. | .. Gāndhāra .. | .. ga |
| Tṛtīya .. | .. Rsabha .. | .. ri |
| Caturtha .. | .. Ṣadja .. | .. sa. |
| Pañcama .. | .. Dhaivata .. | .. dha |
| Sastha .. | .. Nisāda .. | .. ni. |
| Saptama .. | .. Pañcama .. | .. pa |

This identification is made according to a passage occurring in the Nāradaśiksā which is as follows :—

यः सामगानां प्रथमः स वेणोर्मध्यमः स्मृतः ॥
योऽसौ द्वितीयो गान्धारः तृतीयस्त्वृषभः स्मृतः ॥
चतुर्थः षड्ज इत्याहुः पञ्चमो धैवतो भवेत् ।
षष्ठो निषादो विज्ञेयः सप्तमः पञ्चमः स्मृतः ॥

Nāradaśiksā.

The notes of the Sāmavēda and the corresponding notes of the Hindu music are identical with the notes of the English music as shown below :—

| | |
|---|---|
| 1 — 2 — 3 — 4 — 5 — 6 — 7 | Sāmavēda. |
| म - ग - रि - स - ध - नि - प | Hindu music |
| f e d c a b g | English music |

From the way in which the hymns of the Sāma are sung, it appears clearly that *e* is flat. As far as I can ascertain, *b* is also flat. The methods of singing the Sāmavēda are different in different countries, and none of them agree with the figures which are uniformly inserted over the vowels to indicate the notes with which they are to be sung There is a uniformity in the use of these symbols of notes in all the countries; and this method of notation has been handed down to us from a remote period.

To give a musical idea of the chanting of the Sāmavēda, as it ought to be, I give here the first hymn अग्न आयाहि in the Vēdic and musical notations

4 4 4 2 2 2 3 1 1 1 1 2 2 1 1 2 2
ओ ग्रा इ । आ या हीं इ वो इ तो या आ इ । तो या आ इ ।
सा सा स । गा गा ग रि मा म मा मा गा ग । मा मा गा ग
c c c c e e d f f f f e e f f e e

1 1 2 2 2 1 1 1 2 2 1 1 2 2 1 1
गृ णा नो ह । व्य दा तो या आ इ । तो या आ इ । ना इ
मा म गा ग । ग मा मा मा गा ग । मा मा गा ग । मा म
f f e e e f f f e e f f e e f f

2 1 1 2 2 1 2 2 3 2 2 4

हो ता सा आ आ । त्ता आ इ वा आ आ आ

गा मा मा गा री । मा गा ग री गा री सा

e f f e d f e e d e d c

5 5 5 2 2 2 4 5

औ हो वा । हीं इ इ इ षि ॥

धा धा धा । री गा री सा धा ॥

a a a d e d c a

The sixth note of the Sāmavēda, which, as already explained, corresponds to *b* flat, or Kaiśiki Nisāda, and the seventh which corresponds to *g*, or Pañcama, occur very rarely. So, omitting these two sounds, I may say that the melody of the Sāmavēda is uniform and may be identified with the Rāga, called Ābhōgi, which is a derivative Rāga referred to the original Kharaharapriya, and whose notes are स रि ग म ध स.

The above hymn अग्न आयाहि is given in the English notation in Dr. Burnell's edition of the Ārs. Brāham. introduction, pp XLV.

---

## No. 41. सामवेदसंहिता ऋक्पाठः.
## SĀMAVĒDASAMHITĀ RKPĀTHAH.

Substance, palm-leaf Size, $13\frac{3}{4} \times 1\frac{1}{4}$ inches Pages, 168. Lines, 9 on a page. Character, Grantha. Appearance, old. Injured.

Contains the whole of the Pūrvark and 14 Adhyāyas of the Uttarark. At the end of the Pūrvark, the codex contains the

Mahānāmnī which is found at the end of the Pūrvark portion in some manuscripts and not in others.

In this manuscript the hymns are accented by putting the mark ० for the Udātta and the mark for the Svarita in some places, and leaving the Anudātta unmarked.

**Beginning** of the Pūrvark:

अॅग्न आं या हि वीतंये । गृणानो हव्यंदातये । निं होंता सत्सि बर्हिषि ॥

**End:**

सप्तं त्वा हरितो रॅथे वंहन्ति देव सूर्य । शोचिष्केशं विचक्षण ।
ख - 9 ॥ च - 4 ॥ धा - 60 ॥ धौ ॥ पञ्चमः खण्डः ॥
आरुणं समाप्तम् ॥

**Beginning** of the Mahānāmni :

विदां मघवन् विदॉ गातुंमंनुशंसिषो दिशः ॥

**End:**

शूॅरो यॉ गॉषु गच्छति संखा सुशॅवो अॅद्वयुः । महानाम्नी समाप्ता ॥ हरिः ओम् ॥

**Beginning** of the Uttarark :

उंपास्मै गायता नरः पंवमानायेन्दवे । अभीं देवां इंयक्षते ।

**End:**

स्तोता स्यां तव शर्मणि उदग्रे शुचयस्तव । शुक्रा भ्राजन्त ईरते ॥ तव ज्योतींष्यर्चयः . . . . ॥

इति चतुर्दशोऽध्यायः ॥

The following list of the Rsis who composed the Sāmans, which was prepared from the Madras Grantha edition, is given below on account of the philological and historical importance which the names possess, as has been done under the Rgvēda.

| खण्ड: | साम. |
|---|---|
| आग्नेये प्रथमखण्डे— | |
| 1. गौतमः ... ... | 1 |
| कश्यपः ... ... | 1 |
| गौतमः ... ... | 1 |
| सुपर्णः ... ... | 1 |
| विश्वमनाः बृहद्भरद्वाजो वा | 1 |
| श्रुतर्षिः .. . | 3 |
| उशना ... ... | 1 |
| उशना ... ... | 1 |
| शिरीषः उशना वा- . . | 1 |
| इन्द्रः ... . | 2 |
| साकमश्वः शुनश्शेफः | 2 |
| वत्सः काण्वः ... | 2 |
| आग्निः ... . . | 1 |
| सुमित्रो वध्रियश्वः वाध्रियश्वः अनूपो वा | 1 |

| खण्ड | साम |
|---|---|
| 2. अग्निः ... ... | 1 |
| विश्वमनाः ... ... | 1 |
| श्वाभः . ... | 1 |
| श्रुष्टः ... ... | 1 |
| विश्वामित्रः ... ... | 1 |
| अग्निः . . ... | 2 |
| मरुतः ... | 1 |
| भृगुः शुनश्शेफो वा ... | 2 |
| इन्द्रः . . | 1 |
| अग्निः और्वः वैधारयो वा. | 2 |
| अत्रिः ... ... | 1 |
| प्रजापतिः . . ... | 1 |
| 3. सिन्धुक्षित् ... ... | 3 |
| अग्निः ... ... | 2 |
| वामदेवः ... ... | 1 |
| यमः ... ... | 2 |

| खण्डः | | साम. |
|---|---|---|
| | अग्निः ... ... | 2 |
| | त्रिश्वमनाः ... ... | 1 |
| | अग्निः ... ... | 1 |
| | सोमः .. ... | 1 |
| | गोपवनः ... ... | 1 |
| | सूर्यः ... ... | 2 |
| | वसुरोचिः सूर्यवर्चाः<br>वसुरोचिः पारावति<br>वा<br>काशीनो वा<br>कापोतो वा<br>वासुमन्दो वा | 2 |
| | गौतमः<br>गौः अङ्गिरसो वा ... | 2 |
| 4. | भरद्वाजः ... ... | 2 |
| | श्रुष्टिगुः ... ... | 1 |
| | अग्निः वैश्वानरः<br>भरद्वाजो वा ... | 1 |
| | कृतयशाः ... ... | 1 |
| | नृमेधाः कृतवेशो वा... | 1 |
| | कृतवेशः ... ... | 1 |
| | भरद्वाजः ... ... | 2 |
| | उरुः आङ्गिरसः ... | 1 |

| खण्डः | | साम |
|---|---|---|
| | गौतमः ... ... | 2 |
| | मण्डुः जामदग्न्यः ... | 2 |
| | भरद्वाजः ... ... | 1 |
| | गौतमः . ... | 2 |
| | अग्निः ... ... | 2 |
| | आग्निः ... ... | 2 |
| | दीर्घश्रवाः ... ... | 1 |
| 5. | अग्निः ... ... | 2 |
| | गौतमः ... .. | 2 |
| | देवराजः ... ... | 1 |
| | गाथिन् कौशिकः ... | 1 |
| | बृहदुक्थः ... ... | 2 |
| | पुरुमीढः ... ... | 1 |
| | कर्णश्रवाः प्रस्कण्वो<br>वा ... ... | 1 |
| | दिवोदासः ... ... | 1 |
| | सुक्रतुः ... ... | 1 |
| | कण्वः ... ... | 2 |
| | मनुः ... ... | 2 |
| 6. | अग्निः ... ... | 1 |
| | बृहस्पतिः ... ... | 1 |
| | वसिष्ठः ... ... | 1 |

| खण्ड. | | साम |
|---|---|---|
| | विष्पर्धाः आङ्गिरसः ... | 1 |
| | एतवाध्रियः ... ... | 1 |
| | मनः ... ... | 1 |
| | अग्निः वसिष्ठो वा ... | 1 |
| | वारुणः ... ... | 2 |
| | वाम्रः वैखानसः आजीगो वा दानवः | 1 |
| 7. | श्यावाश्वः ... ... | 1 |
| | ऋजुः ... ... | 2 |
| | यमः ... ... | 1 |
| | अग्निः कुत्सो वा यज्ञसारथिर्वा ... | 1 |
| | अग्निर्वैश्वानरः ... | 2 |
| | इटन्वान् ... ... | 2 |
| | वामदवः ... ... | 1 |
| | विश्वज्योतिः... ... | 2 |
| | यमः ... ... | 2 |
| | च्यवनः, शिखण्डी, इन्वकः, वसिष्ठः, प्रजापतिर्वा | 2 |
| 8. | प्रजापतिः ... ... | 1 |
| | शुक्रः ... ... | 1 |

| खण्ड: | | साम |
|---|---|---|
| | पूषा ... ... | 1 |
| | कुत्सः ... | 1 |
| | कश्यपः .. | 2 |
| | घृताचिः आङ्गिरसः ... | 1 |
| | भरद्वाजः ... ... | 1 |
| | अग्निः वैश्वानरः अत्रिर्वा | 1 |
| 9. | पथः ... ... | 2 |
| | अग्निः ... ... | 1 |
| | यमः ... ... | 1 |
| | अग्निः ... ... | 1 |
| | बृहतः कौमुदः ... | 1 |
| | अग्निः ... ... | 3 |
| | प्रजापतिः अत्रिर्वा ... | 2 |
| | श्रुतर्वा ... ... | 1 |
| | इन्द्रः कश्यपो वा ... | 1 |
| 10. | बृहस्पतिः ... ... | 1 |
| | अङ्गिराः यमो वा ... | 1 |
| | असितः ... ... | 2 |
| | त्वष्टा ... ... | 1 |
| | अगस्त्यः ... ... | 1 |
| | मनुः ... ... | 1 |

| खण्डः | | साम |
|---|---|---|
| 11. | तोदः ... ... | 2 |
| | दीर्घतमाः ... ... | 3 |
| | श्यावाश्वः .. ... | 2 |
| | प्रजापतिः ... ... | 5 |
| | त्वष्टा ... ... | 1 |
| | अदितिः ... ... | 1 |
| | वृकजम्भः ... ... | 1 |
| | अगस्त्यः ... ... | 1 |
| | सोमक्रतुः ... ... | 1 |
| | अगस्त्यः ... ... | 1 |
| 12. | इन्द्रः वसिष्ठो वा ... | 2 |
| | इन्द्रः वसिष्ठो वा असितः ... ... | 1 |
| | इन्द्रः वसिष्ठो वा ... | 1 |
| | भरद्वाजः ... ... | 1 |
| | सुभरिः ... ... | 3 |
| | पक्थः सौभरः ... | 2 |
| | देवानीकः ... ... | 1 |
| | साधिः गौतमो वा ... | 1 |
| | जमदग्निः ... ... | 1 |
| | अगस्त्यः ... ... | 1 |

आग्नेयं पर्व समाप्तम् ॥

अथैन्द्रे पर्वणि (वहुसामि).

| खण्ड | | साम. |
|---|---|---|
| 1. | रुद्रः ... ... | 2 |
| | मृगयुः ... ... | 2 |
| | अश्वः ... ... | 1 |
| | इटन्वान् ... ... | 2 |
| | श्रुतकक्षः ... ... | 2 |
| | तन्वः पार्थः .. ... | 1 |
| | दावसुः आङ्गिरसः ... | 1 |
| | वसिष्ठः ... ... | 1 |
| | इडा ... .. | 1 |
| | शर्यातिः ... .. | 3 |
| | इन्द्राणी ... ... | 1 |
| | गौषूक्तिः ... ... | 1 |
| | आश्वसूक्तिः ... ... | 1 |
| | गौरीवितिः .. ... | 1 |
| | गरः ... ... | 3 |
| 2. | सुपर्णः ... ... | 3 |
| | शकलः ... ... | 1 |
| | अभरद्वसुः ... ... | 2 |
| | तन्वः ... ... | 2 |
| | इन्द्रः विश्वामित्रो वा... | 2 |
| | इन्द्राणी ... ... | 2 |
| | इन्द्रः ... ... | 1 |

| खण्डः | | साम |
|---|---|---|
| | दृषनः मारुतः ... | 1 |
| | भरद्वाजः ... ... | 1 |
| | मरुतः ... ... | 1 |
| | भरद्वाजः ... ... | 2 |
| | इध्मवाहः ... ... | 3 |
| | अहिः पैल्वः ... | 1 |
| 3. | इषः ... ... | 1 |
| | पूषा ... ... | 1 |
| | मरुतः सिन्धुर्वा ... | 1 |
| | हविष्मान् ... .. | 2 |
| | हविष्कृत् .. ... | 2 |
| | कक्षीवान् ... ... | 1 |
| | उषः ... ... | 1 |
| | भरद्वाजः ... ... | 2 |
| | भरद्वाजः ऋषभः सिन्धुक्षिद्वा ... ... | 3 |
| | शाकचः ... ... | 2 |
| | वृषन्धरः ... ... | 2 |
| | कुत्सः ... ... | 2 |
| 4. | उपगुः ... ... | 2 |
| | त्वष्टा ... ... | 3 |
| | पषा ... ... | 2 |

| खण्ड | | साम. |
|---|---|---|
| | श्यावाश्वः ... ... | 2 |
| | प्रजापतिः ... ... | 2 |
| | अप्सरसः ... ... | 1 |
| | प्रजापतिः ... .. | 1 |
| | वाजदावर्यः ... ... | 1 |
| | सोमः पूषा ... ... | 1 |
| 5. | वीतहव्यः ... ... | 3 |
| | शाक्त्यः } गौरीविनिर्वा } ... | 6 |
| | कण्वः ... ... | 2 |
| | गौरीवितिः ... | 2 |
| | श्रुतकक्षः ... ... | 1 |
| | सुमित्रः ... ... | 2 |
| | दिवोदासः ... ... | 1 |
| | शाक्वरवर्णः... ... | 1 |
| | रेणुः ... ... | 1 |
| | वीङ्कः ... ... | 1 |
| | उद्लः ... ... | 1 |
| | ऋषभः ... ... | 3 |
| | कुत्सः ... ... | 2 |
| | सुमेधाः ... ... | 3 |
| | देवातिथिः ... ... | 1 |

| खण्ड: | | | |
|---|---|---|---|
| 6. | मुधुच्छन्दा: | ... ... | 1 |
| | क्रौञ्चः | ... ... | 1 |
| | प्रजापति | ... ... | 1 |
| | वभ्रः | ... ... | 3 |
| | गौरीविति: | ... ... | 2 |
| | अकूपारः | ... .. | 2 |
| | धूः | ... ... | 2 |
| | गौरीविति: | ... ... | 1 |
| | वाक् | ... ... | 2 |
| | वामदेवः | ... ... | 1 |
| | इन्द्रः | .. ... | 2 |
| | वामदेवः | ... .. | 1 |
| | आश्विनौ | .. ... | 1 |
| | गोतमः | .. ... | 1 |
| | अश्विनौ | ... ... | 1 |

बहुसामि समाप्तम् ॥

एकसामि—

| | | | |
|---|---|---|---|
| 1. | त्वष्टा | ... ... | 1 |
| | गोधा | ... ... | 1 |
| | सविता | ... ... | 1 |
| | उषा | ... ... | 1 |
| | त्वष्टा | ... ... | 2 |
| | पूषा | ... ... | 1 |

| खण्ड | | | |
|---|---|---|---|
| | इन्द्रः | ... ... | 3 |
| | शुनश्शेफः च्यवनो वा | | 1 |
| | काशीतः | ... ... | 1 |
| 2. | सुमित्रः | ... ... | 1 |
| | श्यावाश्वः | ... ... | 2 |
| | शिखण्डिः | ... ... | 1 |
| | वीतहव्यः | ... .. | 1 |
| | भरद्वाजः | ... ... | 1 |
| | अरुणः वैतहव्यः | ... | 1 |
| | सुभरिः | ... ... | 1 |
| | पष्ठवाट् | ... ... | 1 |
| | साकमश्वः | ... ... | 1 |
| 3 | यमः | ... ... | 1 |
| | अङ्गिरसः | ... ... | 1 |
| | विरूपः | ... ... | 1 |
| | असितः | ... ... | 1 |
| | यमः | ... ... | 1 |
| | सुमित्रः | ... ... | 2 |
| | इन्द्रः | ... ... | 1 |
| | त्वष्टा | ... ... | 1 |
| | पूषा | ... ... | 1 |
| | इन्द्राणी | ... ... | 1 |

| खण्ड: | | | |
|---|---|---|---|
| 4. | श्यावाश्वः | ... ... | 1 |
| | विरूपः | ... ... | 1 |
| | सुमित्रः कुत्सो वा | ... | 1 |
| | तुभः | ... ... | 1 |
| | श्रुनः | ... ... | 1 |
| | अभीशुः | ... ... | 1 |
| | पूषा | ... ... | 1 |
| | इन्द्रः | ... ... | 1 |
| | सुमित्रः | ... ... | 2 |
| 5. | कुत्सः | ... ... | 2 |
| | उषा | ... ... | 1 |
| | भरद्वाजः | ... ... | 1 |
| | कुत्सः | ... ... | 1 |
| | उषा | ... ... | 1 |
| | मित्रावरुणौ | ... ... | 1 |
| | ऋनवः | ... ... | 1 |
| | विष्णुः | ... ... | 1 |
| 6. | कुत्सः | ... ... | 1 |
| | कश्यपः | ... ... | 1 |
| | बृहदुक्थः | ... ... | 2 |
| | कुत्सः | ... ... | 3 |
| | ऊर्ध्वसद्मा | ... ... | 2 |

| खण्डः | | | |
|---|---|---|---|
| | उद्लः अभीपादः | ... | 1 |
| | असहीयुः | ... ... | 1 |

एकसामि समाप्तम् ॥

बृहती—

| | | | |
|---|---|---|---|
| 1. | भरद्वाजः | ... ... | 4 |
| | सन्नतिः | ... ... | 2 |
| | श्यितः | ... ... | 1 |
| | प्रजापतिः | .. ... | 1 |
| | अभीवर्तः आङ्गिरसः | ... | 1 |
| | भगः | ... ... | 1 |
| | इन्द्रः | ... ... | 1 |
| | नोधाः | ... ... | 1 |
| | लुशः | .. ... | 2 |
| | धानाकः | ... .. | 2 |
| | कलिः | ... ... | 3 |
| | इषिरः | ... . . | 2 |
| | गोश्रृङ्गः | ... ... | 2 |
| | प्रजापतिः | ... ... | 1 |
| | जमदग्निः | ... ... | 2 |
| | कुल्मलवर्हिः | ... | 2 |
| | वसिष्ठः | ... .. | 2 |
| | मेधातिथिः देवातिथिर्वा | | 1 |

| खण्ड | | |
|---|---|---|
| 2. | वैश्वानसः | 1 |
| | पुरुहन्मा | 1 |
| | सत्यः | 1 |
| | भरद्वाजः | 1 |
| | भरद्वाजः कण्वो वा | 1 |
| | भरद्वाजः | 2 |
| | वम्रः | 3 |
| | अग्निः | 1 |
| | इन्द्रः | 1 |
| | सप्रः | 2 |
| | इन्द्रः विरूपो वा | 2 |
| | युक्तस्रुक् | 1 |
| | अत्रिः वसिष्ठो वा | 3 |
| | वसिष्ठः अत्रिर्वा | 3 |
| | गोतमः गौराङ्गिरसो वा | 2 |
| 3. | इन्द्रः | 3 |
| | वम्रः | 3 |
| | वरुणः | 3 |
| | प्रजापतिः | 1 |
| | मरुतः | 1 |
| | संश्रवस्, विश्रवस्, सत्यश्रवस्, श्रवस् } इन्द्रो वा | 4 |

| खण्ड | | |
|---|---|---|
| | वम्रः | 2 |
| | वसिष्ठः | 1 |
| | स्वपासिः आङ्गिगः | 2 |
| | कण्वः | 1 |
| | विष्टम्भः | 1 |
| | श्रुष्टीगुः | 1 |
| 4. | इन्द्रः | 1 |
| | द्विगत् | 2 |
| | कृतयशाः कृतवेशो वा | 1 |
| | इन्द्रः | 1 |
| | (प्रजापतिः) | 1 |
| | वम्रः अक्षीलो वा | 1 |
| | वसिष्ठः | 3 |
| | प्रजापतिः | 1 |
| | इन्द्रः | 3 |
| | वसिष्ठः | 3 |
| 5. | पुरुहन्मा | 1 |
| | प्रकर्षः | 1 |
| | इन्द्रः | 1 |
| | कवषः | 2 |
| | सूर्यः | 1 |
| | अनूपः | 2 |

| खण्ड· | | | |
|---|---|---|---|
| | विरूपः ... | ... | 1 |
| | नीपातिथिः ... | . | 2 |
| | बृहत् कौमुदः | ... | 2 |
| | वाक् ... | ... | 1 |
| | वम्रः ... | ... | 2 |
| 6. | गौरीविितिः ... | ... | 2 |
| | अत्रिः ... | ... | 2 |
| | गौरीविितिः ... | .. | 2 |
| | वामदेवः ... | ... | 1 |
| | अश्विनौ ... | ... | 1 |
| | वसिष्ठः ... | ... | 3 |
| | सुभरिः ... | ... | 2 |
| | व्यश्वः . | ... | 1 |
| | प्रजापतिः . | ... | 2 |
| | इन्द्राणी ... | ... | 1 |
| 7. | सुभरिः ... | ... | 1 |
| | गृत्समदः ... | ... | 1 |
| | वाक् ... | ... | 1 |
| | बृहदुक्थः ... | ... | 1 |
| | नीपातिथिः वाग्वा | ... | 1 |
| | तुरश्रवाः ... | ... | 1 |
| | त्वाष्ट्री ... | ... | 1 |
| | अदितिः ... | ... | 1 |

| खण्ड· | | | |
|---|---|---|---|
| | अजीगर्तिः ... | ... | 1 |
| | मधुच्छन्दाः . | ... | 1 |
| 8. | उषा . | ... | 1 |
| | अश्विनौ ... | ... | 3 |
| | सोमः ... | ... | 1 |
| | अजमायुः ... | .. | 1 |
| | प्रियमेधाः समुद्रः | .. | 1 |
| | इन्द्रः वसिष्ठो वा | ... | 1 |
| | विश्वेदेवाः ... | ... | 1 |
| | अथर्वा ... | ... | 1 |

बृहती समाप्ता ॥

त्रिष्टुप्—

| | | | |
|---|---|---|---|
| 1. | प्रकर्षः ... | ... | 1 |
| | वसिष्ठः ... | ... | 1 |
| | गृत्समदः ... | ... | 2 |
| | उरुक्षयः ... | ... | 2 |
| | पृथीः ... | ... | 2 |
| | सुपर्णः ... | ... | 2 |
| | वत्सप्रिः (प्रः) | ... | 3 |
| | गौराविनः ... | ... | 1 |
| | विदन्वान यमो वा | ... | 1 |

खण्डः

| | | |
|---|---|---|
| | यमः . ... | 1 |
| | ऋतः जज्ञानः ब्राह्मो वा | 2 |
| | इन्द्रः .. .. | 1 |
| 2. | इन्द्रः ... ... | 2 |
| | स्यूमरश्मिः . ... | 2 |
| | द्युतानः मारुतः, धृषत् मारुता वा ... | 2 |
| | सोमः ... .. | 2 |
| | इन्द्रः . . | 2 |
| | भृष्टिमान् सूर्यवर्चाः .. | 2 |
| | वसिष्ठः कश्यपो वा ... | 2 |
| | भरद्वाजः ... ... | 1 |
| | विश्वेदेवाः ... ... | 1 |
| | अथर्वा ... | 1 |
| 3. | तार्क्ष्यः अदितिर्वा ... | 2 |
| | इन्द्रः ... ... | 1 |
| | वृत्रतुरे वा यज्ञतुरः ... | 1 |
| | धृषत् मारुतः ... | 2 |
| | अत्रिः ... ... | 1 |

खण्डः

| | | |
|---|---|---|
| | गृत्समदः गौतमो वा ... | 2 |
| | विश्वामित्रः ... ... | 1 |
| | सविता . ... | 6 |
| | विरूपः ... ... | 1 |
| | अमहीयुः ... ... | 1 |

त्रिष्टुप्समाप्ता ॥

अनुष्टुप्

| | | |
|---|---|---|
| 1. | शिखण्डी ... . | 2 |
| | विश्वेदेवाः ... ... | 1 |
| | शिखण्डी .. ... | 3 |
| | अष्टादंष्ट्रः ... ... | 2 |
| | विश्वामित्रः . . | 2 |
| | वसिष्ठः इन्द्रो वा | 1 |
| | गोतमः इन्द्रो वा | 1 |
| | वसिष्ठः इन्द्रो वा | 2 |
| | गृत्समदः वसिष्ठो वा... | 2 |
| | गृत्समदः वसिष्ठो वा अकूपारो वा ... | 1 |
| | गृत्समदः वसिष्ठो वा... | 1 |

* According to the Grantha manuscript printed at Madras, there are only 13 Sāmans in this Khaṇḍa, whereas according to the Arsēyabrāhmaṇa (p 39 of Dr. Burnell's edition) there are 18 with five additional Ṛsis The Madras manuscript has only 3 Sāmans for the Ṛsi सविता and completes the Khaṇḍa.

| खण्ड· | | | |
|---|---|---|---|
| | तिरश्ची आङ्गिरसः | . | 2 |
| | विश्वामित्रः ... | .. | 1 |
| | कण्वः ... | ... | 2 |
| | विश्वामित्रः .. | ... | 1 |
| | इन्द्रः . | ... | 2 |
| | गोतमः ... | ... | 2 |
| 2. | कुल्मलर्बर्हिः | ... | 2 |
| | इन्द्रः आङ्गिरसो वा | ... | 1 |
| | शाकपूतः | ... | 1 |
| | कुल्मलबार्हिः | ... | 2 |
| | प्रजापतिः ... | ... | 1 |
| | उषा ... | ... | 1 |
| | भरद्वाजः ... | ... | 1 |
| | अग्निः ... | ... | 1 |
| | मरुतः मधुच्छन्दा वा | . | 1 |
| 3. | वामदेवः ... | ... | 1 |
| | कश्यपः अप्सरा वा | ... | 1 |
| | प्रियमेधाः .. | ... | 1 |
| | बृहदुक्थः ... | ... | 1 |
| | अग्निः वैश्वानरः | ... | 2 |
| | शाकपूतिः (शकपूतः) | | 2 |
| | वरुणानी ... | ... | 1 |
| | उषा ... | ... | 1 |

| खण्ड· | | | |
|---|---|---|---|
| | रुचिः ... | ... | 1 |
| | ऋक् ... | ... | 1 |
| | साम | .: | 1 |
| 4. | त्रिशोकः ... | ... | 1 |
| | शिखण्डी ... | .. | 2 |
| | अत्रिः ... | ... | 2 |
| | सावेतसः ... | ... | 2 |
| | शिरीषः ... | ... | 2 |
| | इन्द्रः वसिष्ठो वा | ... | 6 |
| | बृहदुक्थः ... | ... | 1 |
| | त्रसदस्युः .. | ... | 2 |
| | सोमः सुभरिर्वा | ... | 1 |
| | सुभरिः ... | .. | 1 |
| | वरुणः द्यावापृथिव्यौ वा ... | ... | 2 |
| | इन्द्रः ... | ... | 1 |
| | विरूपः च्यवनो वा | ... | 1 |

अनुष्टुप्समाप्ता ॥

इन्द्रपुच्छप्रारम्भः—

| | | | |
|---|---|---|---|
| 1. | इन्द्रः } ... | ... | 1 |
| | इन्द्रः } वसिष्ठो वा | ... | 1 |
| | कुत्सः } ... | ... | 1 |

| | खण्डः |
|---|---|
| दिवोदासः . ... | 2 |
| प्रहितुः ... .. | 2 |
| हरिवर्णः .. ... | 4 |
| त्रितः ... .. | 4 |
| आङ्गिरसो वा ... | 1 |
| सुराधसः<br>प्रराधसः } ... | 1 |
| मरुनः आङ्गिरसो वा . | 1 |
| विश्वमनाः . ... | 1 |
| सुमित्रः ... ... | 3 |
| त्रिककुप् ... ... | 3 |
| उक्ष्णोरन्ध्रः ... | 3 |
| 2. प्रजापतिः ... ... | 3 |
| दिवोदासः ... .. | 4 |
| इन्द्रः आङ्गिरसो वा . | 2 |
| यमः ... ... | 1 |
| प्रजापतिः ... ... | 1 |
| भरद्वाजः ... ... | 1 |
| आदित्यः ... ... | 1 |
| इन्द्रः सहोदीर्घतमा वा वसिष्ठो वा प्रजापतिर्वा ... | 2 |

| | खण्डः |
|---|---|
| 3. इन्द्रः .. ... | 1 |
| शार्करः ... ... | 2 |
| बृहत् ... ... | 1 |
| सूयवसः .. ... | 3 |
| मरुतः ... . | 2 |
| इन्द्रः वसिष्ठो वा ... | 2 |
| वायुः ऐषिरः प्रैयमेधो वा | 3 |
| प्रजापतिः ... . | 2 |
| सौभरः पक्थः सौभरिर्वा पथो वा सुभ्रुर्वा ... | 2 |
| 4. यमः ... ... | 1 |
| गृत्समदः ... ... | 2 |
| अभीकः ... .. | 2 |
| अभीशुः ... ... | 2 |
| बृहद्गिरिः .. ... | 3 |
| इन्द्रः ... ... | 1 |
| कश्यपः यमो वा ... | 1 |
| मरुतः ... ... | 1 |
| यमः ... ... | 2 |
| त्रितः ... ... | 3 |
| सुपर्णः ... ... | 2 |
| कुशः ... ... | 1 |

खण्डः

5. इन्द्रः श्रुतो वा श्रुग्मतो वा .. . 2
अङ्गिरसः . ... 2
सत्यश्रवाः वार्यः ... 1
पूषा ... ... 1
उषा ... ... 1
लुशः यमो वा ... 1
अङ्गिरसः ... ... 1
अंहोमुक् गौः आङ्गिरसो वा... ... 1

---

6. इन्द्रः वसिष्ठो वा ... 2
सुहविः ... ... 3
वकः .. ... 3
प्रजापतिः ... ... 4
भगः ... ... 1
वाजिनः ... ... 1
प्रजापतिः ... ... 3
अश्वः इटन्वान् वा ... 2
वाजिनः ... ... 1
आदित्याः ... ... 1

---

7. इन्द्रः वसिष्ठो वा ... 2
वसुमन्दः ... ... 2

खण्डः

कवषः ... ... 3
प्रजापतिः . .. 4
वाक् ... 2
मधुच्छन्दाः ... 1
मरुतः ... ... 1
उद्दंशः ... ... 1

---

8. धूः ... ... 2
प्रजापतिः ... ... 1
विश्वामित्रः ... ... 1
प्रजापतिः ... ... 1
विश्वामित्रः ... ... 1
प्रजापतिः ... 4
उषा ... ... 1
भरद्वाजः ... ... 1
इन्द्रः ... ... 1
भारद्वाजः ... ... 1
इषः ... ... 1
इन्द्रः वसिष्ठो वा प्रजापतिर्वा विद्वा ... 1

---

9. प्रजापतिः .. ... 1
गौः आङ्गिरसः ... 2
प्रजापतिः ... ... 1

खण्ड:

| | | | |
|---|---|---|---|
| प्रजापतिः | ... | .. | 1 |
| यज्ञतुरः | .. | .. | 1 |
| एत्रयामरुत् | . | . | 1 |
| भरद्वाजः सिन्धुक्षिद्वा | | . | 3 |
| सविता | ... | ... | 1 |
| भरद्वाजः परुच्छेपो वा | | | 2 |
| अग्निः वैश्वानरः बृहस्पतिर्वा | | .. | 2 |
| इषः | ... | .. | 1 |

इन्द्रपुच्छं समाप्तम् ॥

पवमानप्रारम्भः—

| | | | |
|---|---|---|---|
| 1. अजिगः | ... | ... | 1 |
| अभीकः | ... | .. | 1 |
| ऋषभः | ... | .. | 1 |
| अभीकः आङ्गिरसः | | ... | 1 |
| बभ्रुः | .. | ... | 2 |
| इन्द्राणी | ... | ... | 1 |
| शिशुः | ... | .. | 2 |
| प्रजापतिः | . | .. | 2 |
| इन्द्राणी | ... | ... | 1 |
| अमहीयुः | ... | ... | 1 |
| अजिगः | ... | .. | 1 |
| सुरूपः | ... | . | 2 |

खण्ड:

| | | | |
|---|---|---|---|
| जमदग्निः | ... | ... | 2 |
| संहितः | ... | .. | 1 |
| वसिष्ठः | .. | ... | 1 |
| जमदग्निः | .. | ... | 1 |
| संहितः | . | . | 1 |
| सोमः | ... | ... | 2 |
| आशुभृगुः | .. | ... | 1 |
| विश्वेदेवाः | | .. | 2 |
| इन्द्राणी | | ... | 2 |
| युक्ताश्वः | ... | . | 2 |
| अत्रिः | ... | ... | 1 |
| सोमः | ... | ... | 1 |
| प्रजापतिः | .. | .. | 1 |
| सोमः | . | ... | 1 |
| आत्रिः | ... | .. | 1 |
| प्रजापतिः | ... | .. | 1 |
| विष्टम्भः | ... | ... | 2 |
| पष्ठवाट् | ... | ... | 2 |
| विष्टम्भः | .. | ... | 1 |
| पष्ठवाट् | ... | ... | 1 |
| प्रजापतिः | ... | ... | 1 |
| इन्द्रः | ... | .. | 1 |
| विश्वेदेवाः | ... | ... | 2 |
| अग्निः | ... | ... | 2 |

| खण्डः | | |
|---|---|---|
| | विश्वेदेवाः ... | 1 |
| | अग्निः .. | 1 |
| | शिशुः .. | 4 |
| | च्यवनः .. | 4 |
| | प्रजापतिः ... | 2 |
| | विदन्वान् .. | 4 |
| | राजिः आङ्गिरसः | 2 |
| | ऊर्णायुः ... | 2 |
| 2. | सुभरः सुभ्रुर्वा | 2 |
| | इन्द्रः ... | 3 |
| | बभ्रुः कौम्भ्यः | 3 |
| | बभ्रुः कार्तवेशः | 3 |
| | शम्मद् इटन्वान्वा | 2 |
| | वसिष्ठः . | 2 |
| | मरुनः ... | 3 |
| | उशना ... | 1 |
| 3. | यमः ... | 3 |
| | अङ्कतिः वैरूपः | 1 |
| | उशना ... | 2 |
| | सोमः ... | 1 |
| | कृष्णः ... | 2 |
| | सोमः } विश्वेदेवाः वा | 1 |
| | सूर्यः } विश्वेदेवाः वा | 1 |

| खण्डः | | |
|---|---|---|
| | इन्द्रः ... | 1 |
| | सोमः ... | 3 |
| | भरद्वाजः . | 1 |
| 4 | वृषाहरिः ... | 1 |
| | वृशः ... | 3 |
| | इन्द्रः ... | 2 |
| | तरन्तः विदद्श्विः | 1 |
| | सोमः ... | 1 |
| | सूर्यः ... | 1 |
| | दृढच्युन् . | 3 |
| | इन्द्रः ... | 1 |
| | इषः ... | 1 |
| | श्यावाश्वः | 1 |
| | अयासोमः सोमो वा | 1 |
| | अग्निः ... | 1 |
| | अयास्यः ... | 2 |
| | भरद्वाजः ... | 1 |
| 5. | अयास्यः ... | 1 |
| | मण्डुः ... | 1 |
| | वसिष्ठः ... | 1 |
| | सोमः वसिष्ठो वा | 1 |
| | अयास्यः ... | 1 |

| खण्डः | |
|---|---|
| मण्डुः ... ... | 1 |
| प्रजापतिः ... ... | 1 |
| अयास्यः ... .. | 1 |
| कण्वः ... | 1 |
| अयास्यः .. | 1 |
| प्रजापतिः .. .. | 1 |
| जमदग्निः ... ... | 2 |
| वसिष्ठः ... ... | 1 |
| रुरुः अग्निः ... ... | 1 |
| { इन्द्रः युधाजिः आङ्गिरसो वा विश्वामित्रः युधाजिर्वा | 1 |
| इन्द्रः वसिष्ठो वा ... | 2 |
| भरद्वाजः ... ... | 2 |
| अभीशुः ... ... | 2 |
| मण्डुः ... ... | 2 |
| अङ्गिरसः ... ... | 2 |
| वेणुः ... ... | 1 |
| सोमक्रतुः मण्डुर्वा ... | 1 |
| प्रजापतिः ... ... | 1 |
| कश्यपः ... ... | 1 |
| आङ्गिरसः ... ... | 2 |
| रुरुः ... ... | 1 |
| युधाजिः ... ... | 1 |
| अश्वः ... ... | 4 |

| खण्डः | |
|---|---|
| अग्निः कुत्सो वा ... | 1 |
| अग्निः वैश्वानरः ... | 2 |
| वामदेवः ... ... | 1 |
| अङ्गिरसः ... ... | 2 |
| सोमः ... ... | 6 |
| विष्णुः ... ... | 2 |
| अङ्गिरसः .. ... | 3 |
| उक्ष्णोरन्ध्रः .. ... | 3 |
| अग्निः ... ... | 3 |
| वभ्रचश्वो वा उक्ष्णोरन्ध्रो वा .. | 1 |
| प्रजापतिः ... ... | 1 |
| विश्वेदेवाः ... ... | 2 |
| इन्द्रः ... ... | 2 |
| अङ्गिरसः ... ... | 1 |
| इन्द्रः ... ... | 3 |
| सोमः ... ... | 2 |
| अङ्गिरसः .. ... | 1 |
| सोमः ... ... | 2 |
| आदित्यः ... ... | 1 |

---

| | |
|---|---|
| 6. उशना ... ... | 5 |
| वराहः ... ... | 4 |

| खण्डः | | | |
|---|---|---|---|
| | अङ्गिरसः | ... ... | 3 |
| | सामसुराः | ... ... | 2 |
| | वेणुः | ... ... | 2 |
| | गोतमः | ... ... | 2 |
| | अगस्त्यः | ... ... | 2 |
| | इन्द्रः | ... ... | 2 |
| | वसिष्ठः | ... ... | 9 |
| | वसिष्ठः | ... ... | 2 |
| | व्यश्वः | ... ... | 1 |
| | सोमः | ... ... | 2 |
| | इषः | ... ... | 1 |
| | मधुच्छन्दाः | ... ... | 1 |

| खण्डः | | | |
|---|---|---|---|
| 7. | कुत्सः | ... ... | 3 |
| | विश्वज्योतिः | ... | 3 |
| | वाक् | ... ... | 2 |
| | दशस्पतिः | ... ... | 2 |
| | कश्यपः | ... ... | 1 |
| | दशस्पतिः | ... ... | 4 |
| | श्रुष्टिः आङ्गिरसः | ... | 3 |
| | अत्रिः | ... ... | 1 |
| | वसिष्ठः | ... ... | 1 |
| | आपः | ... ... | 1 |

| खण्डः | | | |
|---|---|---|---|
| 8. | नकुलः<br>वामदेवः | ... | 2 |
| | कृतयशाः कृतवेशो वा | | 1 |
| | ऊर्ध्वसद्मा | ... ... | 1 |
| | श्यावाश्वः | ... ... | 1 |
| | अन्धीगुः | ... ... | 1 |
| | क्रुङ् | ... ... | 3 |
| | त्वाष्ट्री | ... ... | 2 |
| | वसिष्ठः | ... ... | 1 |
| | त्वाष्ट्रयः | ... ... | 1 |
| | वसिष्ठः | ... ... | 1 |
| | त्वाष्ट्रयः | ... ... | 2 |
| | वसिष्ठः | ... ... | 1 |
| | क्रुङ् | ... ... | 2 |
| | सोमः | ... ... | 3 |
| | क्रुङ् | ... ... | 1 |
| | सोमः | ... ... | 1 |
| | अङ्गिरसः | ... ... | 3 |
| | गृत्समदः | ... ... | 4 |
| | अकूपारः | ... ... | 1 |
| | विरूपः नृगो वा | ... | 1 |

| खण्डः | | | |
|---|---|---|---|
| 9. | कविः | ... ... | 1 |
| | वाजसनिः | ... ... | 2 |

| खण्डः | | | | |
|---|---|---|---|---|
| | वाजजित् | ... | ... | 2 |
| | कविः | ... | ... | 1 |
| | भृगुः | ... | ... | 1 |
| | अङ्गिरसः | ... | ... | 2 |
| | सामराजः | ... | ... | 2 |
| | सामा | ... | ... | 1 |
| | वसिष्ठः | ... | ... | 1 |
| | लुशः | ... | ... | 2 |
| | भृगुः | ... | ... | 1 |
| | विरूपः | ... | ... | 1 |
| | यमः | ... | ... | 1 |
| | दासशिराः | ... | ... | 2 |
| | यमः | ... | ... | 3 |
| | मरुतः | ... | ... | 1 |
| | इन्द्रः | ... | ... | 1 |
| | वायुः | ... | ... | 1 |
| | यमः | ... | ... | 3 |
| | मरुतः | ... | ... | 1 |
| | अञ्जतः कक्षीवान् | | ... | 1 |
| | व्यञ्जतः कक्षीवान् | | ... | 1 |
| | समञ्जतः कक्षीवान् | | ... | 1 |
| | आदित्यः | ... | ... | 2 |
| 10. | वसिष्ठः | ... | ... | 2 |
| | वसिष्ठः | ... | ... | 2 |
| | पुष्कलः | ... | ... | 1 |
| | इषिरः | ... | ... | 5 |
| | शुक्तिः | ... | ... | 5 |
| | कर्णश्रवाः | ... | ... | 3 |
| | वाक् | ... | ... | 2 |
| | इन्द्रः | ... | ... | 2 |
| | मरुतः | ... | ... | 1 |
| | प्रजापतिः | ... | ... | 2 |
| | इन्द्रः | ... | ... | 2 |
| | द्युनः | ... | ... | 2 |
| | प्रजापतिः | ... | ... | 2 |
| | सोमः | ... | ... | 7 |
| | भरद्वाजः | ... | ... | 1 |
| 11. | वसिष्ठः | ... | ... | 1 |
| | देवाः | ... | ... | 2 |
| | वसिष्ठः | ... | ... | 1 |
| | देवाः | ... | ... | 1 |
| | इषिरः | ... | ... | 4 |
| | कर्णश्रवाः | ... | ... | 3 |
| | वाक् | ... | ... | 3 |
| | कुल्मलबर्हिः | | ... | 2 |
| | प्रजापतिः | ... | ... | 1 |

खण्डः

| | | |
|---|---|---|
| कुल्मलबर्हिः | ... | 3 |
| भरद्वाजः | ... ... | 2 |
| सोमः | ... ... | 3 |
| शीतोष्मः | ... ... | 4 |
| देवाः | ... ... | 2 |
| सोमः | ... ... | 3 |

पवमानं समाप्तम् ॥

अथारण्यकर्षयः ॥

प्रथमपर्व—

| | | |
|---|---|---|
| 1. विरूपः प्रजापतिः | ... | 8 |
| प्रजापतिः | ... ... | 2 |
| देवाः | ... ... | 2 |
| प्रजापतिः | ... ... | 2 |

| | | |
|---|---|---|
| 2. वरुणः | ... ... | 1 |
| प्रजापतिः | ... ... | 1 |
| वरुणः | ... ... | 2 |
| अङ्गिराः | ... ... | 2 |
| बृहस्पतिः | ... ... | 1 |
| भरद्वाजः | ... ... | 1 |
| अथर्वा | ... ... | 1 |

खण्डः

| | | |
|---|---|---|
| नरद्वसुः | ... ... | 1 |
| वामदेवः | ... ... | 2 |
| भरद्वाजः | ... ... | 1 |

| | | |
|---|---|---|
| 3. वसिष्ठः | ... ... | 1 |
| जमदग्निः | ... ... | 1 |
| स्वाशिराः | ... ... | 1 |
| दीर्घतमाः | ... ... | 1 |
| मरुतः | ... ... | 2 |
| अग्निः | ... ... | 1 |
| प्रजापतिः | ... ... | 1 |
| इन्द्रः | ... ... | 2 |
| अर्कः | ... ... | 2 |
| वरुणः गौतमश्च | ... | 1 |
| प्रजापतिः | ... ... | 2 |

| | | |
|---|---|---|
| 4. आग्निः वैश्वानरः | ... | 3 |
| रुद्रः | ... ... | 4 |
| इन्द्रः | ... ... | 1 |
| इन्द्रः | ... ... | 1 |
| प्रजापतिः | ... ... | 1 |
| गोतमः | ... ... | 1 |
| विश्वामित्रः | ... ... | 1 |
| इन्द्राग्नी वा | ... ... | 1 |

| खण्ड: | | |
|---|---|---|
| 5. अग्निः | ... ... | 1 |
| पृथिवी | ... ... | 1 |
| वायुः | ... ... | 1 |
| अन्तरिक्षः | ... ... | 1 |
| आदित्यः | ... ... | 1 |
| द्यौः | ... ... | 1 |
| आपः | ... ... | 1 |
| समुद्रः | ... ... | 1 |
| मण्डुः | ... ... | 2 |

| | | |
|---|---|---|
| 6 प्रजापतिः | ... ... | 8 |
| शाकरवर्णः | ... ... | 1 |
| प्रजापतिः | ... ... | 1 |
| वसिष्ठः | ... ... | 1 |
| जमदग्निः | ... ... | 1 |

| | | |
|---|---|---|
| 7. शार्वः | ... ... | 2 |
| रुद्रः | ... ... | 3 |
| अग्निः | ... ... | 2 |
| क्षुरः | ... ... | 2 |
| मृत्युः | ... ... | 1 |
| वामदेवः | ... ... | 1 |
| इन्द्रः | ... ... | 1 |

| खण्ड: | | |
|---|---|---|
| अग्निः | ... ... | 1 |
| प्रजापतिः | ... ... | 2 |

प्रथमपर्व समाप्तम् ॥

द्वितीयपर्व—

| | | |
|---|---|---|
| 1. वसिष्ठः | ... ... | 2 |
| इन्द्रः | ... ... | 2 |
| प्रजापतिः | ... ... | 2 |
| इन्द्राणी | ... ... | 2 |
| बृहस्पतिः इन्द्रो वा | ... | 2 |

| | | |
|---|---|---|
| 2. प्रजापतिः | ... ... | 2 |
| यमः | ... ... | 2 |
| प्रजापतिः | ... ... | 5 |
| वृषाहरिः | ... ... | 3 |

| | | |
|---|---|---|
| 3. द्युतः | ... ... | 2 |
| तत्पन्द्रः | ... ... | 2 |
| तुरश्रवाः | ... ... | 2 |
| प्रजापतिः | ... ... | 4 |

| | | |
|---|---|---|
| 4. प्रजापतिः | ... ... | 4 |
| रायोवाजः | ... ... | 1 |
| बृहद्गिरिः | ... ... | 1 |

खण्डः

| | | |
|---|---|---|
| | देवाः ... ... | 1 |
| | पृथुरश्मिः ... ... | 1 |
| | प्रजापतिः ... ... | 2 |
| 5. | प्रजापतिर्भुवनः ... | 2 |
| | प्रजापतिः ... ... | 4 |
| | वृकजम्भः ... ... | 2 |
| | प्रजापतिः ... ... | 2 |
| 6 | प्रजापतिः ... ... | 2 |
| | यमः ... ... | 1 |
| | मधुच्छन्दाः ... ... | 1 |
| | वसिष्ठः ... ... | 2 |
| | प्रजापतिः ... ... | 2 |
| 7. | वायुः ... ... | 6 |
| | वायुश्च विष्णुः ... | 5 |
| | विष्णुः वायुश्च ... | 6 |

तृतीयपर्व—

| | | |
|---|---|---|
| 1. | वाक ... ... | 2 |
| | शशः ... ... | 1 |
| | प्रजापतिः ... ... | 3 |
| | परमेष्ठी प्राजापत्यः ... | 1 |

खण्डः

| | | |
|---|---|---|
| | अङ्गिराः ... ... | 1 |
| | सोमः ... ... | 2 |
| 2. | भरद्वाजः ... ... | 2 |
| | यमः ... ... | 1 |
| | अङ्गिरसः ... ... | 1 |
| | अश्विनौ ... ... | 2 |
| | गावः ... ... | 2 |
| | कश्यपः ... ... | 2 |
| 3. | अङ्गिरसः ... ... | 2 |
| | आपः ... ... | 2 |
| | अहः } रात्रिः } ... ... | 2 |
| | विष्णुः ... ... | 1 |
| | विश्वेदेवाः ... ... | 1 |
| | वसिष्ठः ... ... | 2 |
| 4. | इन्द्रः ... ... | 1 |
| | अगस्त्यः ... ... | 1 |
| | प्रजापतिः ... ... | 2 |
| | जमदग्निः ... ... | 2 |
| | इन्द्रः ... ... | 1 |
| | प्रजापतिः ... ... | 1 |
| | इन्द्रः ... ... | 2 |

| खण्डः | | |
|---|---|---|
| 5. | अग्निः ... ... | 5 |
| | रुद्रः ... ... | 2 |
| | विश्वेदेवाः ... ... | 1 |
| | प्रजापतिः .. ... | 2 |
| | सोमः ... ... | 1 |
| | दीर्घनमाः ... .. | 1 |
| 6. | पुरुषः ... ... | 6 |
| | द्यौः ... ... | 1 |
| | अन्तरिक्षः ... ... | 1 |
| | पृथिवी ... ... | 1 |
| | कश्यपः ... ... | 1 |
| 7. | दिशः ... ... | 10 |
| 8. | कश्यपः ... ... | 4 |
| | कश्यपः प्रजापतिः ... | 1 |
| | कश्यपः इडः ... | 1 |
| | कश्यपः गावः ... | 2 |
| | कश्यपः प्रजापतिः ... | 2 |

आरण्यकं समाप्तम् ॥

शुक्रियप्रारम्भः ॥

| खण्डः | | |
|---|---|---|
| 1. | अग्निः ... ... | 1 |
| | वायुः ... ... | 1 |
| | वैश्वानरः ... ... | 2 |
| | सूर्यः ... ... | 2 |
| | वायुः मृत्युर्वा ... | 2 |
| | इन्द्रः ... ... | 1 |
| | विश्वेदेवाः चित्रदेवाश्च | 1 |
| 2. | सूर्यः ... ... | 3 |
| | इन्द्रः ... ... | 1 |
| | मरुतः ... ... | 1 |
| | सर्पराजानः ... ... | 3 |
| | घर्मः ... ... | 1 |
| | इन्द्रः ... ... | 1 |
| 3. | इन्द्रः ... ... | 5 |
| | ऋतवः .. ... | 1 |
| | मित्रावरुणौ ... ... | 1 |
| | इन्द्रः ... ... | 1 |
| | आदित्यः .. ... | 1 |

महानाम्नी.

| | | |
|---|---|---|
| | इन्द्रः ... ... | 6 |

## No. 42. सामवेदसंहिता ऋक्पाठः.

## SĀMAVĒDASAṀHITĀ ṚKPĀṬHAḤ.

Substance, paper. Size, 12½ × 8 inches. Pages, 153. Lines, 18 on a page. Character, Telugu. Appearance, new. In good condition.

The other work contained in this manuscript is Audgātraprayōgaḥ (fol. 82*a*).

Contains the Pūrvarḳ and the Uttararḳ complete, except the Āruna and the Śukriya. No accentuation.

**Beginning** of the Pūrvarḳ:

अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥

**End:**

एषस्य धारया सुतो ऽव्यावारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥ य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा । अभि व्रजंतत्निषे गव्यमश्वियं वर्मीव धृष्णवा रुज ॥ एकादशः खण्डः समाप्तः । पवमानं समाप्तम् ॥

**Beginning** of the Uttararḳ:

उपास्मै गायत । नरः पवमानायेन्दवे । अभिदेवाँ इयक्षते ॥

**End:**

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ एकविंशोऽध्यायः ॥ उत्तरऋक्समाप्ता ॥

उपद्विपवा । अग्न आनो मित्र । . . . सर्भिम एकविंश एकविंशः ॥

## No. 43. सामवेदसंहिता ऋक्पाठः.
## SĀMAVĒDASAMHITĀ ṚKPĀṬHAḤ.

Substance, palm-leaf. Size, 14 × 1¼ inches. Pages, 250. Lines, 5 on a page. Character, Grantha. Appearance, old. Slightly injured.

Contains the Pūrvaṛk complete, without Mahānāmnī; and the Uttaraṛk.

**Beginning** of the Pūrvaṛk:

अग्न आयाहि . . . . . . . . . .

**End:**

शोचिष्केशं विचक्षण ॥ 25 ॥ शुक्रियं समाप्तम् ॥

As the order in which the verses of the Uttaraṛk are arranged follows the arrangement of the corresponding Sāmans in Ūha and Rahasya, the opening passage as given in this manuscript differs from that given in No. 41. Only those Ṛcas of the Sāmans of Ūha and Rahasya, which do not occur in the Pūrvaṛk are given here.

**Beginning** of the Uttaraṛk:

उच्चा ते जातमन्धसः । स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवो वित्परिस्रव ॥ येना विश्वान्यर्य आ द्युम्नानि मानुषाणां । सिषासन्तो वनामहे ॥ . . . . . . . . . .

**End:**

विड् (वीडु)चिद्यस्य समृतौ ष्वयद्वय (श्रुवद्वनेव यत्) स्थिरम् निष्षहमाणो यमते नायते धन्वासहा नायते ।

---

## No. 44. सामवेदसंहिता ऋक्पाठः.
## SĀMAVĒDASAMHITĀ ṚKPĀṬHAḤ

Substance, palm-leaf. Size, 12⅓ × 1½ inches. Pages, 44. Begins on folio 8*a*. Lines 8, on a page. Character, Grantha. Condition, injured. Appearance, old..

Contains the first 6 Adhyāyas of the Uttaraṛk. The arrangement of the Ṛcas is not like that of the Sāmans but follows a

different order. The other work in this manuscript is Ūhachalākṣaraḥ.

## No. 45. सामवेदसंहिता ऋक्पाठः.
## SĀMAVĒDASAṀHITĀ ṚKPĀṬHAḤ.

Substance, palm-leaf. Size, 15½ × 1½ inches. Pages, 48. Lines, 6 on a page. Characters, Kanarese, Nandināgarī and Grantha. Injured and old.

Contains the Pūrvaṛk from Āgnēya to the end of Indrapuccha The last leaf is numbered 29; folios 8 to 12 are lost. This contains also . . . . . Dṛṣṭimantraḥ (Kanarese language) (folio, 25*a*). Prakṛtichalākṣaraḥ (folio 27*a*). Chandōgōtsarjanavidhiḥ (folio 31*a*), a collection of Rcas from Prakṛti (folio 38*a*).

## No. 46. सामवेदगानम् प्रकृतिः.
## SĀMAVĒDAGĀNAM - PRAKṚTIḤ.

Substance, palm-leaf (Śrītāḷa) Size, 9½ × 2 inches. Pages, 421. Lines, 9 on a page. Character, Grantha. Appearance, old. In excellent order.

Complete. This belongs to the C. W. Whish series.

The codex contains the whole of the Prakṛti.

**Beginning:**

गौतमस्य पर्कः ॥ ओ त ग्राइ । आ छो याहो ण वोइतोया प्र इ। तो का या प्रे इ । गृ का णाँनों हा । व्या चो दा तोया प्रे इ । तो का या प्रे इ । ना धी इहोंतासा । त्सा व इवाऔहोंवा । ही टू षी । दी. 7 ; प. 9 ; मा. 9. झो ॥ 1 ॥

**End:**

त क रैं योभ । भा का गों मा ही प्रे ॥ धि छ यों यों नः प्राचो त्रिः । हिं का आ प्रे । दा क यो । आ कू । दी. 6 ; प. 6 ; मा. 2. का ॥ आम् . . . . . अबद्धं वा सुबद्धं वा मम दोषो न विद्यते . , . ॥

# INDEX.

[NOTE.—The names printed in *italics* are those of works that are described.]


| | PAGE |
|---|---|
| Abhiśravaṇam ... ... | 38 |
| Adhikārasaṅgrahaḥ ... | 56 |
| Aditisūktam ... ... | 50 |
| Advaitamakarandaḥ ... | 44 |
| Aghamarṣaṇasūktam ... | 38 |
| Aghōranārasimhōccāṭanam. | 41 |
| Āgnēyam ... ... | 71, 72, 73, 74, 80, 83, 104 |
| Agnihōtraprayōga ... | 31 |
| Ahīnaḥ ... ... ... | 72, 74 |
| Aikāhaḥ ... ... ... | 72, 74 |
| Aindram ... ... ... | 72, 73, 74, 83 |
| Aitarēya ... ... ... | 69 |
| Aitarēyabrāhmaṇa ... | 59, 60, 61, 65, 66, 67, 68, 69 |
| Aitarēyāraṇyaka ... ... | 60 |
| Aitarēyōpaniṣad ... ... | 69 |
| Ākarṣaṇagrahaḥ ... ... | 41 |
| Alfred Ludwig ... ... | 2 |
| Ānanda ... ... ... | 36, 41, 44 |
| Ānandatīrtha ... ... | 32, 57, 59 |
| Anēkārthadhvanimañjarī . | 52 |
| Aṅgapūjā ... ... ... | 40 |
| Añjanam ... ... ... | 40 |
| Anuṣṭup ... ... ... | 71, 72, 73, 89, 90 |
| Āpastambaparibhāṣāvyākhyā | 44 |
| Āraṇyaka ... ... | 9 |
| Āraṇyapadapāṭha ... | 76 |
| Āraṇyaparva ... ... | 50 |
| Ārṣēyabrāhmaṇa ... | 72, 74, 80, 89 |
| Ārṣṭiṣēṇaḥ ... ... | 50 |
| Āruṇam ... ... ... | 71, 72, 73, 74, 98, 101, 102 |
| Asādhyālu ... ... | 40 |
| Āśvalāyana ... ... | 69 |
| Āśvalāyana-Gṛhya-Pariśiṣṭa | 9 |
| Aśvamēdha ... ... | 8 |
| Atharvaṇōpaniṣadbhāṣyam. | 57 |
| Atharva Vēda ... ... | 35 |
| Audgātraprayōgaḥ ... | 102 |
| Aufrecht, Th. ... ... | 1, 61 |
| Bādarāyaṇa ... ... | 49, 51 |
| Bādarāyaṇasūtram ... | 53 |
| Bagaḷā Ēkākṣarī ... | 42 |
| Bagaḷākavacaḥ ... ... | 42 |
| Bagaḷāmahālakṣmīmantra. | 40 |
| Bagaḷāmahālakṣmīmūlam. | 42 |
| Bagaḷāmālā ... ... | 42 |
| Bagaḷāmantraḥ ... ... | 42 |
| Bagaḷāmukhīcaturakṣarī. | 42 |
| Bagaḷāmukhīmālā ... | 42 |
| Bagaḷāmukhīmantraḥ ... | 42 |
| Bagaḷāmukhīpancavidhānam. | 40 |
| Bagaḷāmukhīstōtram ... | 42 |
| Bagaḷāmukhīvidhānam ... | 42 |
| Bagaḷāmukhyapūjā ... | 42 |
| Bagaḷānuṣṭhanavidhiḥ ... | 42 |
| Bagaḷānyāsaḥ ... ... | 42 |
| Bagaḷāpūjā ... ... | 42 |
| Bagaḷāṣṭākṣarī ... ... | 42 |
| Bagaḷāstavaḥ ... ... | 42 |
| Bahusāmi ... ... | 71, 72, 73, 83, 85 |
| Bahvṛcabrāhmaṇa ... | 59, 61, 62 |
| Bālagrahalakṣaṇamu ... | 41 |
| Bālagraharāvaṇīyaśāstramu. | 41 |
| Bālagrahayantrālu ... | 41 |
| Bālaśāstramu ... ... | 41 |
| Balidravyālu ... ... | 41 |

| | PAGE |
|---|---|
| Balisthānālu ... ... | 40 |
| Bāṣkala Śākhā ... ... | 2 |
| Benfey ... ... ... | 74 |
| Bhadrādrirāmaśatakamu. | 42 |
| Bhagavadgītā ... ... | 53 |
| Bhairavōccāṭanam ... | 40 |
| Bhandarkar, Dr. ... ... | 2 |
| Bhaviṣyōttaram ... ... | 53 |
| Bhaviṣyōttara Purāṇa ... | 51 |
| Bhúśuddhi ... ... | 42 |
| Bhūśuddhimantraḥ ... | 55 |
| Bhūsūktam ... ... | 34, 38 |
| Bhūtacikitsālu ... ... | 40 |
| Bhūtaśuddhimahāmantraḥ. | 55 |
| Bibliotheca ... ... | 61 |
| Bibliotheca Indica ... | 32, 64, 69 |
| Bōdhāyanaḥ ... ... | 50, 53 |
| Bōdhāyana Gṛhya ... | 34 |
| Boppanabhaṭṭīyam ... | 43 |
| Brāhmam ... ... ... | 34, 48 |
| Brāhmapurāṇam ... | 50 |
| Brahmarākṣasagrahalākṣaṇamu | 39 |
| Bṛhatī ... ... ... | 71, 72, 73, 86, 88 |
| Bühler ... ... ... | 5 |
| Burnell, Dr. ... ... | 74, 89 |
| Canakadurumantrālu ... | 41 |
| Chandōgōtsarjanavidhiḥ . | 104 |
| Chandōnirṇaya ... ... | 31 |
| Chāyāpuruṣalakṣaṇam ... | 35 |
| Ciklīta ... ... ... | 36, 41, 44 |
| Colebrooke ... ... | 99 |
| Daityagrahalakṣaṇamu ... | 39 |
| Dakṣiṇāmūrtikavacaḥ ... | 56 |
| Dakṣiṇāmūrtyaṣṭōttaraśatam. | 56 |
| Darśapūrṇamāsaḥ ... | 44 |
| Daśarātra ... ... ... | 72, 73, 74 |
| Daśaśāntiḥ ... ... | 35 |

| | PAGE |
|---|---|
| Dattātrēyadvādaśanāmāni. | 40 |
| Dattātrēyasahasranāma. | 40 |
| Dēvatāgrahalakṣaṇamu. | 39 |
| Dēvībhāgavatam ... | 45 |
| Dēvīstavaḥ ... ... | 35 |
| Dēvyaṣṭōttaraśatanāmāni. | 56 |
| Dhanadīyam ... ... | 51 |
| Dhūmāvtīkalpaḥ ... | 40 |
| Dhūmāvatīmālāmantraḥ. | 40 |
| Dhūmāvatīmūlamantraḥ. | 40 |
| Dṛṣṭimantra ... ... | 104 |
| Duṣṣahaḥ ... ... ... | 51 |
| Eggeling ... ... ... | 69 |
| Ēkāmrēśvarāṣṭakam ... | 35 |
| Ēkasāmi ... ... ... | 71, 72, 73, 85, 86 |
| Gaḍḍakarigōmantramu ... | 41 |
| Gaṇahōmaḥ ... ... | 44 |
| Gaṇapatidvādaśanāmāni. | 56 |
| Gaṇapatyaṣṭōttaraśatanāmāni. | 56 |
| Gandharvagrahalakṣaṇamu. | 39 |
| Gandharvavicāraḥ Savyākhyaḥ. | 37 |
| Garuḍadvādaśanāmāni ... | 56 |
| Gautamagṛhyapariśiṣṭa ... | 34 |
| Gāyatrībhujaṅgaḥ ... | 55 |
| Gāyatrībrahmāstraprayōganyāsamantraḥ ... | 55 |
| Gāyatrīcaturvimśatinyāsaḥ | 55 |
| Gāyatrīghṛtamu ... ... | 40 |
| Gāyatrīhṛdayam ... | 55 |
| Gāyatrīkavacaḥ ... ... | 55 |
| Gāyatrīmantrarājaḥ ... | 55 |
| Gāyatrīpañjaram ... | 55 |
| Gāyatrī-Sāvitrī-Sarasvatī Tarpaṇavidhiḥ ... | 55 |
| Gāyatrīvandanastōtram... | 55 |
| Gāyatrīvyākhyā ... ... | 44 |
| Gāyatrīyantram ... ... | 55 |
| Gāyatryaṣṭōttaraśatanāmāni. | 55 |

| | PAGE |
|---|---|
| Ghṛtasūktam ... ... | 34 |
| Gōpālāṣṭōttaraśatam ... | 56 |
| Gōpālaṣṭōttaraśatanāmāni. | 56 |
| Grahadhūpamu ... ... | 40 |
| Grahanasyāñjanamu ... | 40 |
| Grahanirṇayamu ... | 39 |
| Grahāñjanamu ... ... | 40 |
| Griffith ... ... ... | 2 |
| Gurunādhunipampu ... | 41 |
| Gurupādukātrayamantraḥ. | 56 |
| Hall, Dr. ... ... | 44 |
| Hanumaddvādaśanāmāni. | 56 |
| Hanumadrāmāyaṇa ... | 52 |
| Hanumadyantraḥ with Tel. Ṭīkā | 56 |
| Hanumanmālāmantraḥ ... | 44, 56 |
| Hanumatkavacaḥ ... | 40 |
| Haradatta ... ... | 45, 46 |
| Hariharatāratamyam ... | 52 |
| Haug, Dr. ... ... | 61 |
| Hermann Grāssman ... | 2 |
| Hiraṇyadēvīsūktam ... | 39 |
| History of Indian Literature. | 5 |
| Indrapuccham ... ... | 4, 10, 71, 72, 73, 90, 93 |
| Iṅgilīkamsinamu ... | 40 |
| Iṅguvādighṛtamu ... | 40 |
| Īśāvāsyōpaniṣadbhāṣyam. | 57 |
| Īśvarasamhitā ... ... | 51 |
| Itarā ... ... ... | 59, 60 |
| Jayādihōmaprayōgaḥ ... | 37 |
| Jayatīrtha ... ... | 32 |
| Kākagrahalakṣaṇamu ... | 40 |
| Kardama ... ... ... | 36, 41, 44 |

| | PAGE |
|---|---|
| Kāśyapīya ... ... | 51, 53 |
| Kāṭhakōpaniṣadbhāṣyam. | 57 |
| Kauṣītaka ... ... | 61 |
| Kauṣītakī Brāhmaṇa ... | 60 |
| Khadgamālā ... ... | 40 |
| Kirātavārāhīkalpaḥ ... | 40 |
| Kṛṣṇasvāmi Śrautin ... | 74 |
| Kṣudraḥ ... ... ... | 72, 74 |
| Kūṣpāsadhūpamu ... | 40 |
| Kūṣmāṇḍagrahalakṣaṇamu | 40 |
| Laiṅgam ... ... ... | 51, 53 |
| Laiṅgēkṣepastōtram ... | 50 |
| Lakṣmīgaṇapatimantraḥ | 56 |
| Lakṣmīsahasranāmāvaliḥ. | 42 |
| Lalitāsahasranāmāvaliḥ. | 24 |
| Liṅgapūjāvidhih ... ... | 56 |
| Mādhavīya ... ... | 33, 65, 66, 68 |
| Mādhavācārya ... ... | 44, 45 |
| Mahābhārata ... ... | 48, 51 |
| Mahāmantraniruktabrāhmaṇam. | 62 |
| Mahānamnī ... ... | 71, 74, 79, 91, 103 |
| Mahānāṭakam ... ... | 52 |
| Mahāsaṅkalpaḥ ... ... | 56 |
| Mahīdāsa ... ... ... | 59, 60 |
| Maitrāyaṇīsaṁhitā ... | 5 |
| Maitrēyaparāśarasamvādaḥ | 50 |
| Malayāḷabhagavatī ... | 42 |
| Māṇḍūkyōpaniṣadbhāṣyam. | 57 |
| Maṅkaṇasaṁhitā ... | 49, 51, 53 |
| Mārkandēyam ... ... | 53 |
| Max Müller, F. ... | 2, 9, 11, 32, 44, 69 |
| Mēdhāsūktam ... ... | 50 |
| Miscellaneous Essays ... | 69 |
| Mlēcchagrahaḥ ... ... | 40 |
| Mullakarigōmantrālu ... | 41 |

| | PAGE |
|---|---|
| Namakam ... ... | 33 |
| Nāmamālā ... ... | 51, 53 |
| Nāradaśikṣā ... ... | 76 |
| Nāradīyam ... ... | 53 |
| Narasimhamantraḥ ... | 56 |
| Nārāyanahṛdayastōtram. | 55 |
| Nasyacikitsālu ... ... | 40 |
| Navagrāhaśāntiḥ ... | 37 |
| Navaratrikalpaḥ ... ... | 42 |
| Navōnavōbhavatītiśruty-arthavicāraḥ ... ... | 56 |
| Nidhidarśanam ... ... | 40 |
| Nikṣēpacintāmaṇiḥ ... | 56 |
| Nikṣēpagrahōccāṭanamu. | 40 |
| Nīlakaṇṭhavijayḥ ... | 52 |
| Nityārādhanakramaḥ ... | 42 |
| Pādarasabandhanamantramu. | 40 |
| Pādarasaśuddhiḥ ... | 40 |
| Padaratnam ... ... | 70 |
| Pādmapurāṇam ... ... | 51 |
| Paiṅgya ... ... ... | 61 |
| Pañcaṣāntiḥ ... ... | 34 |
| Pañcasimhāsanēśvarīsūktam. | 55 |
| Pañcāstrapūjā ... ... | 40 |
| Pañcavaktrahanumanmantrah | 56 |
| Pāpapuruṣadahanam ... | 55 |
| Paramātmasūkta ... | 49, 51 |
| Parāśarasmṛtih ... ... | 44 |
| Pārthivaliṅgapūjāvidhiḥ. | 37 |
| Pārthivapūjāvidhiḥ ... | 56 |
| Pāṣāṇabandhaḥ ... | 40 |
| Pāśupatāstram ... ... | 35, 39, 40 |
| Pātrasthāpanam ... ... | 40 |
| Pāvamanām ... ... | 71, 72, 73, 74, 93, 98, 102 |
| Piśācagrahalakṣaṇamu ... | 39 |
| Prakṛti ... ... ... | 71, 72, 73, 74, 104 |
| Prakṛtichālākṣara ... | 104 |
| Prāṇapratiṣṭhā ... | 55 |
| Prasūtigolēnivarikimantrālu. | 41 |

| | PAGE |
|---|---|
| Pratyaṅgirāmahālakṣmīmantrah. | 39 |
| Pratyaṅgirāmahāyantrakalpaḥ. | 39 |
| Pratyaṅgirāmālā ... | 36 |
| Pratyaṅgirāmālāmantraḥ. | 39 |
| Pratyaṅgirāmantraḥ ... | 55 |
| Pratyaṅgirāvyākhyānam. | 39 |
| Prāyaścittam ... ... | 72, 74 |
| Prētagrahalakṣaṇamu ... | 39 |
| Pṛthvīdharācārya ... | 45, 54 |
| Pṛthvīsūktam ... ... | 50 |
| Puruṣasūktam ... ... | 34, 35, 37, 38 |
| Pūrvārcika ... ... | 74 |
| Pūrvāṛk ... ... .. | 71, 73, 74, 78, 79, 102, 103, 104 |
| Rahasya ... ... ... | 72, 73, 74, 103 |
| Rājadharma ... ... | 48, 51 |
| Rājasvajanavaśyamu ... | 43 |
| Rajendra Lala Mitra ... | 61, 64, 69 |
| Rākṣasadigbandhaḥ ... | 39 |
| Rākṣasagrahalakṣaṇamu. | 39 |
| Rāmakavacaḥ ... ... | 40 |
| Rāmānujadāsa ... ... | 51 |
| Rāmaṣaḍakṣarī ... ... | 40 |
| Rāmayaṇam ... ... | 51 |
| Raṅganātha, Gōmaṭha ... | 47, 50 |
| Raṅganāthamuni ... | 46, 51 |
| Rasabandhamūlikālu ... | 40 |
| Rasasahasravidhaḥ ... | 40 |
| Rasaśudhiḥ (Tel.) ... | 40 |
| Ratnapradīpikā ... ... | 40 |
| Rātrisūkta ... ... | 9 |
| Raudraḥ ... ... ... | 34 |
| *Ṛgbhāṣyam* ... ... | 57, 59 |
| Ṛgvēda ... ... | 1, 3, 4, 5, 9, 11, 25, 26, 27, 28, 29, 30, 32, 34, 44, 57, 59, 61, 62, 69, 71, 74, 75, 76 |
| *Ṛgvēdabhāṣyam* ... ... | 32 |

| | PAGE |
|---|---|
| *Ṛgvēdabrāhmaṇabhāṣyam.* | 62, 64, 67, 68 |
| *Ṛgvēdabrāhmaṇam* ... | 59, 62, 63, 65, 67, 68 |
| Ṛgvēdāmnāya ... ... | 63 |
| Ṛgvēdanighaṇṭu ... ... | 62 |
| Ṛgvēdapādānukramaṇikā. | 70 |
| *Ṛgvēdapadapātha* ... | 26, 27, 28, 29, 30, 31 |
| Ṛgvēdapadasaṅkhyā ... | 31 |
| Ṛgvēdaprātassandhyāvandanam ... ... | 42 |
| *Ṛgvēdāraṇyakam* ... | 69 |
| *Ṛgvēdāruṇam* ... ... | 62, 70, 71 |
| *Ṛgvēda Saṁhitā* ... ... | 1, 2, 6, 7, 8, 10, 26, 33 |
| Ṛoer, Dr. ... ... ... | 32 |
| Rudramantraḥ ... ... | 41 |
| Rudrāṣṭōttaraśatanāmāvaliḥ. | 39 |
| Rudravidhānam ... ... | 55 |
| Śābarabandhaḥ ... ... | 41 |
| Śābaramantraḥ ... ... | 40, 41 |
| Śābaramantrālu ... ... | 39 |
| Ṣadvarṇamantrāṣṭakam. | 35 |
| Ṣadvidyāgamaḥ ... ... | 42 |
| Sakalagrahadhūpaḥ ... | 41 |
| Śākala Śākhā ... ... | 2, 10 |
| Śākalya Śākhā ... ... | 60 |
| Śāktamantrāgamah ... | 55 |
| Śaktimantraḥ ... ... | 40 |
| Sāma Saṁhitā ... ... | 74 |
| Sāmavēda ... ... | 4, 34, 71, 74, 75, 76, 77, 78, 80 |
| *Sāmavēdasaṁhitā-Ṛkpāṭhaḥ.* | 78, 102, 103, 104 |
| Sāma-Vidhāna-Brāhmaṇa. | 74 |
| Sāmudrikaśāstram ... | 52 |
| Samvatsara ... ... | 72, 73, 74 |
| Sanatkumāraḥ ... ... | 50 |
| Sandhyāvandanabhāṣyam. | 47 |
| Śāṅkhārcanam ... ... | 40 |
| Sāṅkhyāyanabrāhmaṇa. | 60 |
| Sāṅkhyāyanatantraḥ ... | 42 |
| Śāpavimōcanamantraḥ ... | 55 |
| Saptasaṅkhyā ... ... | 70 |
| Saptaśatī ... ... | 35 |
| Śarabhakalākarṣaṇamālikā. | 56 |
| Śarabhasāḷuvamantraḥ ... | 55 |
| Śarabhāṣṭōttaraśatanyāsaḥ. | 55 |
| Sarasvatīstavarājaḥ ... | 56 |
| Sarasvatyaṣṭōttaraśatanāmāvaliḥ. | 55 |
| Śārīrakamīmāṁsāsūtrakāra. | 49, 51 |
| Sarvarakṣā ... ... | 40 |
| Śatānanda ... ... | 45 |
| Ṣaṭpraśnōpaniṣadbhāṣyam. | 57 |
| Satram ... ... ... | 72, 74 |
| Śatruvidhvamsinīśūlinī. | 40 |
| Satyavratasamāśramin ... | 74 |
| Satyavratasvāmin ... | 61, 64 |
| Sāyaṇa ... ... ... | 2, 69, 74 |
| Sāyaṇācārya ... ... | 32, 33, 60, 64, 66, 67, 68 |
| Siddhārtaghṛtamu ... | 40 |
| Simhānuvākaḥ ... ... | 44 |
| Simhānuvakavyākhyānam. | 44 |
| Sītāṣṭōttaraśatanāmāvaliḥ. | 42 |
| Śivagaṇapatistōtram ... | 56 |
| Śivāṣṭōttaraśatanāmāni ... | 56 |
| Śivastutiḥ ... ... | 35 |
| Śivōmēgāyatryeṣṭakam. | 35 |
| Śraddhāsūkta ... ... | 47, 50 |
| Śrāddhavidhiḥ ... ... | 44 |
| Śrīkaṇṭha ... ... | 45 |
| Śrīstutivyākhyā ... ... | 46 |
| *Śrīsūktabhāṣyam* ... | 43, 46, 50, 51, 52 |
| *Śrīsūktam* ... ... | 34, 35, 37, 38, 39, 42, 44, 47, 51 |
| *Śrīsūktavyākhyā* .. | 52, 53, 55, 56 |
| Śrīsūktōddhāraḥ ... | 39 |
| Steevenson, Rev. J. ... | 74 |

PAGE

Śuddhaśaktikhadgamālāstōtram. 55
Śukraśāpavimōcanam ... 40
Śukriyam ... ... 71, 72, 73, 74, 101, 102
Śulinīmantraḥ ... ... 55
Sumaṅgalasūkta ... 9
Śūnyamcampumantramu. 39
Sūryāṣṭōttaraśatanāmāni. 56
Svaracintāmaṇiḥ Śaṭīkaḥ. 42
Svaraśāstrasaṅgrahaḥ ... 42
Svāyambhuvam ... ... 50, 53

Taittirīyāraṇyaka ... 69
Taittirīya Śākhā ... 3
Talavakārōpaniṣadbhāṣyam. 57
Tarkasaṅgrahavyākhyā. 54
Tṛṣṭūp ... ... ... 71, 72. 73, 88, 89
Tryambakanyāsaḥ ... 56

Ucchiṣṭagaṇapatiḥ ... 40
Ūhachalākṣaram ... 104
Ūhaḥ ... ... ... 72, 73, 74, 103
Uṅgiṭimantramu ... 41
Uragagrahalakṣaṇamu ... 39, 40
Uttarark ... ... 71, 72, 73, 74, 78, 79, 102, 103, 104
Uttarasandhyāmṛtyulāṅgalastōtram 55
Uttarāyaṇamantramu ... 40

Vāgbandhanamu ... 40
Vaidyacintāmaṇi ... 40
Vaiṣṇavapurāṇa ... ... 48, 50
Vavasūktam ... ... 50
Vāmanapurāṇa ... ... 45

PAGE

Vanadurgāmahālakṣmīmantraḥ. 39
Vanadurgāstōtram ... 56
Varāhōpaniṣad ... ... 56
Vāruṇam ... ... 34
Vāruṇasūktam ... ... 38
Vasiṣṭhasmṛtiḥ ... ... 50
Vdārthaprakāśaḥ ... 32, 33, 65, 66, 68
Vēdataijasam ... ... 43
Vēṅkaṭādrikṛṣṇarāya ... 52
Vētāḷagrahalakṣaṇamu ... 40
Vētāḷamantraḥ ... ... 40
Vibhūtidhāraṇam ... 55
Vidyādhara ... ... 44
Vidyāraṇyasvāmin ... 44
Vidyātīrtha ... ... 33
Vidyātīrtha Mahēśvara ... 44, 45
Vighnēśāṣṭakam ... 40
Vighnēśvaradvādaśanāmastōtram. 37
Vighnēśvaramālāmantraḥ. 40
Vināyakastōtraśatam ... 37
Vīrabukka ... ... 32
Vīrapratāpahanumanmālāmantraḥ. 40
Vīrapratāpahanumanmantraḥ 40
Viṣṇu Purāṇa ... ... 35, 53
Viṣṇusahasranāma ... 44
Viṣṇusmṛtiḥ ... ... 50
Vyāsaśikṣā ... ... 43
Vyāsaśikṣāvyākhyā ... 43

Weber ... ... ... 5, 74
Wörterbuch Zum Rigvēda. 2

Yājamānam ... ... 44
Yajurvēda ... ... 5, 74, 76
Yakṣagrahalakṣaṇamu ... 39
Yama ... ... ... 48, 51
Yāskaḥ ... ... ... 45